नामलिंगानुशा
-सँन नाम

7094
Divo→Dev

VI-52

7094
[illegible]

2326

Basthi Pundalika Shenoy.
ASHOKNAGAR.
MANGALORE-6.

Basthi Pundalika Shenoy.

॥ श्रीः ॥

नामलिंगानुशासनं नाम
अमरकोशः
श्रीमदमरसिंहविरचितः

॥ प्रथमं कांडम् ॥

यस्य ज्ञानदयासिन्धोः अगाधस्यानघा गुणाः
सेव्यतां अक्षयो धीराः स श्रिये चामृताय च ॥१॥
समाहृत्यान्यतंत्राणि संक्षिप्तैः प्रतिसंस्कृतैः ।
संपूर्णमुच्यते वर्गैः नामलिंगानुशासनम् ॥२॥
प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् ।
स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥३॥
भेदाख्यानाय न द्वंद्वो नैकशेषो न संकरः ।
कृतोत्र भिन्नलिंगानां अनुक्तानां क्रमादृते ॥४॥

त्रलिंग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति।
षिद्धलिंगं शेषार्थं त्वंताथादि न पूर्वभाक् ॥५॥

स्वर्गवर्गः ॥

वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः।
रलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्

अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः।
सुपर्वाणः सुमनसः त्रिदिवेशाः दिवौकसः॥६॥

आदितेया दिविषदो लेखा अदितिनंदनाः।
आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतांधसः ॥८॥

बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः॥
वृंदारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥९॥

दित्यविश्ववसवःतुषिताऽऽभास्वरानिलाः
हाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥१०॥

द्याधराऽप्सरोयक्षरक्षोगंधर्वकिन्नराः।
शाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥११॥

असुरा दैत्यदैतेयदनुजेंद्रारिदानवाः।
शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥१२

सर्वज्ञःसुगतो बुद्धो धर्मराजस्तथागतः।
समंतभद्रो भगवान् मारजिल्लोकजिज्जिनः।

षडभिज्ञो दशबलोऽद्वयवादी विनायकः।
मुनींद्रः श्रीघनःशास्तामुनिःशाक्यमुनिस्तु यः ॥

शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः।
तमश्चार्कबंधुश्च मायादेवीसुतश्च सः॥१५॥

ह्मात्मभू सुरज्येष्ठः परमेष्ठी पितामहः।

रण्यगर्भो लोकेशः स्वयंभूश्चतुराननः॥१६॥

ताब्जयोनिद्रुहिणो विरिंचि कमलासनः
ष्टा प्रजापतिर्वेधा विधाता विश्वसृड्विधिः॥१७॥

भिजन्मांडजः पूर्वो निधनः कमलोद्भवः॥
दानंदो रजोमूर्तिः सत्यको हंसवाहनः॥)

वष्णुर्नारायणः कृष्णो वैकुंठो विष्टरश्रवाः।
दामोदरो हृषीकेशः केशवो माधवः स्वभूः॥१८॥

2324

सोली स्वक्षेडता वयस्थाऽथ मकूलकः ॥
म्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि ॥ १४४ ॥
मोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका ॥
पुष्करकाश्मीरपद्मपत्राणि पौष्करे ॥ १४५ ॥
यथाऽतिचरा पद्मा चारटी पद्मचारिणी ॥
म्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि ॥ १४६ ॥
न्नाडस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः ॥
ट उरणाख्यश्च पलाण्डुस्तु सुकन्दकः ॥ १४७ ॥
र्कदुद्रुमौ तत्र हरितेऽथ महौषधम् ॥
शुनं गृञ्जनारिष्टमहाकन्दरसोनकाः ॥ १४८ ॥
र्नवा तु शोथघ्नी वितुन्नं सुनिषण्णकम् ॥
द्वातकः शीतलोऽपराजिता शणपर्ण्यपि ॥ १४९ ॥
रावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता ॥
र्षिकं त्रायमाणा स्यात्त्रायन्ती बलभद्रिका १५०
ष्वक्सेनाप्रिया गृष्टिर्वाराही बदरेत्यपि ॥
र्कवो भृङ्गराजः स्यात्काकमाची तु वायसी ॥ १५१ ॥
तपुष्पा सितच्छत्राऽतिच्छत्रा मधुरा मिसिः ॥
वाक्पुष्पी कारवी च सरणा तु प्रसारिणी ॥ १५२ ॥
स्यां कटंभरा राजबला भद्रबलेत्यपि ॥
नी जतूका रजनी जतुकृच्चक्रवर्तिनी ॥ १५३ ॥
स्पर्शाऽथ शटी गन्धमूली षड्ग्रन्थिकेत्यापि ॥
र्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः ॥ १५४ ॥

सुषवी चाथ कुलकं पटोलस्तिक्तकः पटुः ॥
कूष्माण्डकस्तु कर्कारुरुर्वारुः कर्कटी स्त्रियौ ॥ १५ ॥
इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलाबूरुभे समे ॥
चित्रा गवाक्षी गोडुम्बाविशाला त्विन्द्रवारुणी ॥ १५६ ॥
अर्शोघ्नः सूरणः कन्दो गण्डीरस्तु समष्ठिला ॥
कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका ॥ १५७ ॥
वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका ॥
सहस्रवीर्याभार्गव्यौ रुहाऽनन्ताऽथ सा सिता ॥ १५८ ॥
गोलोमी शतवीर्या च गण्डाली शकुलाक्षका ॥
कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ॥ १५९ ॥
स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा ॥
वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः ॥ १६० ॥
शतपर्वा यवफलो वेणुमस्करतेजनाः ॥
वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ॥ १६१
ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः ॥
नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम् ॥ १६
इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः ॥
रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः ॥ १
स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रि
अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १
लामज्जकं लघुलयमवदाहेष्टकापथे ॥
नडादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि ॥ १६५ ॥

कुशं कुथो दर्भः पवित्रमथ कत्तृणम् ॥
गन्धिकध्यामदेवजग्धकरौहिषम् ॥ १६६ ॥
तेच्छत्रपालघ्नौ मालातृणकभूस्तृणे ॥
बालतृणं घासो यवसं तृणमर्जुनम् ॥ १६७ ॥
ां संहतिस्तृण्या नड्या तु नडसंहतिः ॥
जाह्वयस्तालो नालिकेरस्तु लाङ्गली ॥ १६८ ॥
तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु ॥
गमेते च हिन्तालसहितास्त्रयः ॥ १६९ ॥
केतकी ताली खर्जूरी च तृणद्रुमाः ॥
गु ॥ इति वनौषधिवर्गः ॥ ४ ॥
र्निव न्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः ॥
द्वात गारिपुर्मृगदृष्टिर्मृगाशनः ॥
रावताड श्वनखचित्रकायमृगद्विषः ॥ १ ॥)
षिंकं त्रा व्याघ्रे तरक्षुस्तु मृगादनः ॥ १ ॥
ष्वक्सेनाप्रि ष्टिः कोलः पोत्री किरिः किटिः ॥
कवो भृङ्गरा रोमा क्रोडो भूदार इत्यपि ॥ २ ॥
तपुष्पा सितच्छ वलीमुखाः ॥
वाक्पुष्पी कारवी वनौका अथ भल्लुके ॥ ३ ॥
स्यां कटंभरा राज [illegible] खड्गखड्गिनौ ॥
नी जतूका रज[illegible]हद्विषत्कासरसैरिभाः ॥ ४ ॥
स्पर्शोऽथ भूरिमायगोमायुमृगधूर्तकाः ॥
चूरोऽपि क्रोष्टुफेरुफेरवजम्बुकाः ॥ ५ ॥

औतुर्बिडालो मार्जारो वृषदंशक आखुभुक् ।
त्रयो गौधेरगौधारगौधेया गोधिकात्मजे ॥ ६ ॥
श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम् ॥
वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः ॥ ७ ॥
मृगे कुरङ्गवातायुहरिणाजिनयोनयः ॥
ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु ॥ ८ ॥
कदली कन्दली चीनश्चमूरुप्रियकावपि ॥
समूरुश्चेति हरिणा अमी अजिनयोनयः ॥ ९ ॥
कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः ॥
गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ १० ॥
गन्धर्वः शरभो रामः सृमरो गवयः शशः ॥
इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११
(अधोगन्ता तु खनको वृषः पुंध्वज उन्दुरः)
उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका ॥
सरटः कृकलासः स्यान्मुसली गृहगोधिका ॥ १२ ॥
लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः ।
नीलङ्गुस्तु कृमिः कर्णजलौकाः शतपद्युभे ॥ १३ ॥
वृश्चिकः शूककीटः स्यादालिद्रुणौ तु वृश्चिके ॥
पारावतः कलरवः कपोतोऽथ शशादनः ॥ १४ ॥
पत्री श्येन उलूकस्तु वायसारातिपेचकौ ।
(दिवान्धः कौशिको घूको दिवाभीतो निशाटनः ॥
व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः ॥ १५

हपृष्ठस्तु कङ्कः स्यादथ चाषः किकीदिविः ॥
लिङ्गभृङ्गधूम्याटा अथ स्याच्छतपत्रकः ॥ १६ ॥
र्वाघाटोऽथ सारङ्गस्तोककश्चातकः समाः ॥
कवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ॥ १७ ॥
कः कलविङ्कः स्यात्तस्य स्त्री चटका तयोः ॥
पत्ये चाटकैरस्त्र्यपत्ये चटकैव सा ॥ १८ ॥
करेटुः करेटुः स्यात्कृकणक्रकरौ समौ ॥
प्रियः परभृतः कोकिलः पिक इत्यपि ॥ १९ ॥
के तु करटारिष्टबलिपुष्टसकृत्प्रजाः ॥
ङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि ॥ २० ॥
स एव च चिरंजीवी चैकदृष्टिश्च मौकुलिः ॥)
णकाकस्तु काकोलो दात्यूहः कालकण्ठकः ॥
तायिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ ॥ २१ ॥
ङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः ॥
कश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः ॥ २२ ॥
दम्बः कलहंसः स्यादुत्क्रोशकुररौ समौ ॥
ास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः ॥ २३ ॥
जहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः ॥
लिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः ॥ २४ ॥
रारिराटिराडिश्च बलाका बिसकण्ठिका ॥
सस्य योषिद्वरटा सारसस्य तु लक्ष्मणा ॥ २५ ॥
तुकाऽजिनपत्रा स्यात्परोष्णी तैलपायिका ॥

वर्वणा मक्षिका नीला सरघा मधुमक्षिका ॥ २६॥
पतङ्गिका पुत्तिका स्याद्दंशस्तु वनमक्षिका ॥
दंशी तज्जातिरल्पा स्याद्गन्धोली वरटा द्वयोः ॥ २७ ॥
भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः ॥
समौ पतङ्गशलभौ खद्योतो ज्योतिरिङ्गणः ॥ २८ ॥
मधुव्रतो मधुकरो मधुलिण्मधुपालिनः ॥
द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः ॥ २९ ॥
मयूरो बर्हिणो बर्ही नीलकण्ठो भुजंगभुक् ॥
शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३० ॥
केका वाणी मयूरस्य समौ चन्द्रकमेचकौ ॥
शिखा चूडा शिखण्डस्तु पिच्छबर्हे नपुंसके ॥ ३१ ॥
खगे विहंगविहगविहंगमविहायसः ॥
शकुन्तिपक्षिशकुनिशकुन्तशकुनाद्विजाः ॥ ३२ ॥
पतत्त्रिपत्त्रिपतगपतत्पत्त्ररथाण्डजाः ॥
नगौकोवाजिविकिरविविष्किरपतत्त्रयः ॥ ३३ ॥
नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसंगमाः ॥
तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः ॥ ३४ ॥
तित्तिरिः कुक्कुभो लावो जीवजीवश्चकोरकः ॥
कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः ॥ ३५ ॥
गरुत्पक्षच्छदाः पत्त्रं पतत्त्रं च तनूरुहम् ॥
स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरुभे स्त्रियौ ॥ ३६ ॥
प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः ॥

शी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम् ॥ ३७ ॥
ोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः ॥
ीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगुलं युगम् ॥ ३८ ॥
मूहनिवहव्यूहसंदोहविसरव्रजाः ॥
तोमौघनिकरव्रातवारसंघातसंचयाः ॥ ३९ ॥
मुदायः समुदयः समवायश्च यो गणः ॥
स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ ४० ॥
ृन्दभेदाः समैर्वर्गः सङ्घसार्थौ तु जन्तुभिः ॥
सजातीयैः कुलं यूथं तिरश्चां पुंनपुंसकम् ॥ ४१ ॥
पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम् ॥
स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् ॥ ४२ ॥
कापोतशौकमायूरतैत्तिरादीनि तद्गणे ॥
गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ॥ ४३ ॥

॥ इति सिंहादिवर्गः ॥ ५ ॥

मनुष्या मानुषा मर्त्या मनुजा मानवा नराः ॥
स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः ॥ १ ॥
स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः ॥
प्रतीपदर्शिनी वामा वनिता महिला तथा ॥ २ ॥
विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना ॥
प्रमदा मानिनी कान्ता ललना च नितम्बिनी ॥ ३ ॥
सुन्दरी रमणी रामा कोपना सैव भामिनी ॥

कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः ॥
पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ॥ ५ ॥
भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी ॥
पुरंध्री सुचरित्रा तु सती साध्वी पतिव्रता ॥ ६ ॥
कृतसापत्निकाध्यूढाधिविन्नाथ स्वयंवरा ॥
पतिंवरा च वर्याथ कुलस्त्री कुलपालिका ॥ ७ ॥
कन्या कुमारी गौरी तु नग्निकाऽनागतार्तवा ॥
स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे ॥ ८ ॥
समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी ॥
इच्छावती कामुका स्याद्वृषस्यन्ती तु कामुकी ॥ ९ ॥
कान्तार्थिनी तु या याति संकेतं साऽभिसारिका ॥
पुंश्चली धर्षिणी बन्धक्यसती कुलटेत्वरी ॥ १० ॥
स्वैरिणी पांशुला च स्यादशिश्वी शिशुना विना ॥
अवीरा निष्पतिसुता विश्वस्ताविधवे समे ॥ ११ ॥
आलिः सखी वयस्याऽथ पतिवत्नी सभर्तृका ॥
वृद्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती ॥ १२ ॥
शूद्री शूद्रस्य भार्या स्याच्छूद्रा तज्जातिरेव च ॥
आभीरी तु महाशूद्री जातिपुंयोगयोः समा ॥ १३ ॥
अर्याणी स्वयमर्या स्यात्क्षत्त्रिया क्षत्त्रियाण्यपि ।
उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः ॥ १४ ॥
आचार्यानी पुंयोगे स्यादर्यी क्षत्त्रियी तथा ॥
उपाध्यायान्युपाध्यायी पोटा स्त्रीपुंसलक्षणा ॥ १५ ॥

त्नी वीरभार्या वीरमाता तु वीरसूः ॥
ापत्या प्रजाता च प्रसूता च प्रसूतिका ॥ १६ ॥
नग्निका कोटवी स्याद्दूतीसंचारिके समे ॥
ायन्यर्धवृद्धा या काषायवसनाऽधवा ॥ १७ ॥
ध्री परवेश्मस्था स्ववशा शिल्पकारिका ॥
क्री स्यादवृद्धा या प्रेष्याऽन्तःपुरचारिणी ॥ १८ ॥
स्त्री गणिका वेश्या रूपाजीवाऽथ सा जनैः ॥
कृता वारमुख्या सात्कुट्टनी शम्भली समे ॥ १९ ॥
श्निका त्वीक्षणिका दैवज्ञाऽथ रजस्वला ॥
धर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि ॥ २० ॥
ुमत्यप्युदक्यापि स्याद्रजः पुष्पमार्तवम् ॥
द्धालुर्दोहदवती निष्कला विगतार्तवा ॥ २१ ॥
पन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी ॥
गकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे ॥ २२ ॥
र्भूर्दिधिषूरूढा द्विस्तस्या दिधिषुः पतिः ॥
तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी ॥ २३ ॥
नीनः कन्यकाजातः सुतोऽथ सुभगासुतः ॥
भागिनेयः स्यात्पारस्त्रैणेयस्तु परस्त्रियाः ॥ २४ ॥
ृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः ॥
ो मातृष्वसुश्चैवं वैमात्रेयो विमातृजः ॥ २५ ॥
थ बान्धकिनेयः स्याद्बन्धुलश्चासतीसुतः ॥
ौलटेरः कौलटेयो भिक्षुकी तु सती यदि ॥ २६ ॥

तद्वा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः ॥
आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रियां त्वमी ॥ २७ ॥
आहुर्दुहितरं सर्वेऽपत्यं तोकं तयोः समे ॥
स्वजाते त्वौरसौरस्यौ तातस्तु जनकः पिता ॥ २८ ॥
जनयित्री प्रसूर्माता जननी भगिनी स्वसा ॥
ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा ॥ २९ ॥
भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ॥
प्रजावती भ्रातृजाया मातुलानी तु मातुली ॥ ३० ॥
पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः ॥
पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुलः ॥ ३१ ॥
श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनो देवृदेवरौ ॥
स्वस्रीयो भागिनेयः स्याज्जामाता दुहितुः पतिः ॥ ३२ ॥
पितामहः पितृपिता तत्पिता प्रपितामहः ॥
मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः ॥ ३३ ॥
समानोदर्यसोदर्यसगर्भ्यसहजाः समाः ॥
सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥ ३४ ॥
ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः ॥
धवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ ॥ ३५ ॥
अमृते जारजः कुण्डो मृते भर्तरि गोलकः ॥
भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६ ॥
मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ ॥
श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च ॥ ३७ ॥

ती जंपती जायापती भार्यापती च तौ ॥
र्भाशयो जरायुः स्यादुल्बं च कललोऽस्त्रियाम् ॥ ३८ ॥
तिमासो वैजननो गर्भो भ्रूण इमौ समौ ॥
तीयाप्रकृतिः षण्ढः क्लीबः पण्डो नपुंसके ॥ ३९ ॥
शुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे ॥
यात्स्थाविरं तु वृद्धत्वं वृद्धसङ्घेऽपि वार्धकम् ॥ ४० ॥
लितं जरसा शौक्ल्यं केशादौ विस्रसा जरा ॥
यादुत्तानशया डिम्भा स्तनपा च स्तनंधयी ॥ ४१ ॥
ालस्तु स्यान्माणवको वयस्थस्तरुणो युवा ॥
वयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ४२ ॥
र्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः ॥
घन्यजे स्युः कनिष्ठयवीयोवरजानुजाः ॥ ४३ ॥
अमांसो दुर्बलश्छातो बलवान्मांसलोंऽसलः ॥
तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः ॥ ४४ ॥
अवटीटोऽवनाटश्चाऽवभ्रटो नतनासिके ॥
केशवः केशिकः केशी बलिनो बलिभः समौ ॥ ४५ ॥
विकलाङ्गस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः ॥
खरणाः स्यात्खरणसो विग्रस्तु गतनासिकः ॥ ४६ ॥
खुरणाः स्यात्खुरणसः प्रज्ञुः प्रगतजानुकः ॥
ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात्संज्ञुः संहतजानुकः ॥ ४७ ॥
स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः ॥
पृश्निरल्पतनौ श्रोणः पङ्गौ मण्डस्त मण्डिते ॥ ४८ ॥

बलिरः केकरे खोडे खञ्जस्त्रिषु जरावराः ॥
जडुलः कालकः पिप्लुस्तिलकस्तिलकालकः ॥ ४९ ॥
अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया ॥
भेषजौषधभैषज्यान्यगदो जायुरित्यपि ॥ ५० ॥
स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः ॥
क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः ॥ ५१ ॥
स्त्री क्षुत् क्षुतं क्षवः पुंसि कासस्तु क्षवथुः पुमान् ॥
शोफस्तु श्वयथुः शोथः पादस्फोटो विपादिका ॥ ५२ ॥
किलाससिध्मे कच्छ्वां तु पामपामे विचर्चिका ॥
कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम् ॥ ५३ ॥
व्रणोऽस्त्रियामीर्ममरुः क्लीबे नाडीव्रणः पुमान् ॥
कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी ॥ ५४ ॥
आनाहस्तु निबन्धः स्याद्ग्रहणीरुक् प्रवाहिका ॥
प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः ॥ ५५ ॥
व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगंदराः ॥
(श्लीपदं पादवल्मीकं केशघ्नस्त्विन्द्रलुप्तकः)
अश्मरी मूत्रकृच्छ्रं स्यात्पूर्वे शुक्रावधेस्त्रिषु ॥ ५६ ॥
रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके ॥
वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् ॥ ५७ ॥
ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः ॥
आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ ॥ ५८ ॥
दद्रुणो दद्रुरोगी स्यादर्शोरोगयुतोऽर्शसः ॥

ो वातरोगी स्यात्सातिसारोऽतिसारकी ॥ ५९ ॥
न्नाक्षेचुल्लँचिल्लपिल्लाः क्लिन्नेऽक्ष्णिचाप्यमी ॥
त उन्मादवति श्लेष्मलः श्लेष्मणः कफी ॥ ६० ॥
ो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ ॥
सी सिध्मलोऽन्धोऽदृङ्मूर्छाले मूर्तमूर्छितौ ॥ ६१ ॥
तेजोरेतसी च बीजवीर्येन्द्रियाणि च ॥
पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा ॥ ६२ ॥
तं तरसं मांसं पललं क्रव्यमामिषम् ॥
 शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम् ॥ ६३ ॥
रेऽसृग्लोहितास्रक्तक्षतजशोणितम् ॥
ग्रमांसं हृदयं हृन्मेदस्तु वपा वसा ॥ ६४ ॥
द्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा ॥
कं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम् ॥ ६५ ॥
त्रं पुरीतत् गुल्मस्तु प्लीहा पुंस्यथ वस्नसा ॥
युः स्त्रियां कालखण्डयकृती तु समे इमे ॥ ६६ ॥
णका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम् ॥
ासामलं तु सिङ्घाणं पिञ्जूषं कर्णयोर्मलम् १)
 मस्त्राव उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥
ीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ ॥
त्कर्परः कपालोऽस्त्री कीकसं कुल्य मस्थि च ॥ ६८ ॥
च्छरीरास्थ्नि कंकालः पृष्ठास्थ्नि तु कशेरुका ॥
करोटिः स्त्री पार्श्वास्थनि तु पर्शुका ॥ ६९ ॥

अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् ॥
गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥
कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ॥
पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम् ॥ ७१ ॥
तद्ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः ॥
जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम् ॥ ७२ ॥
सक्थि क्लीबे पुमानूरुस्तत्संधिः पुंसि वङ्क्षणः ॥
गुदं त्वपानं पायुर्ना बस्तिर्नाभेरधो द्वयोः ॥ ७३ ॥
कटो ना श्रोणि फलकं कटिः श्रोणिः ककुद्मति ॥
पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः ॥ ७४
कूपकौ तु नितम्बस्थौ द्वयहीने कुकुन्दरे ॥
स्त्रियां स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः ॥ ७५
भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी ॥
मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम् ॥ ७६ ॥
पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ ॥
चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् ॥ ७७
उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः ॥
स्कन्धो भुजाशिरोंऽसोऽस्त्री संधी तस्यैव जत्रुणी ॥ ७८
बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः ॥
मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः ॥ ७
भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः ॥
अस्योपरि प्रगण्डः

न्धादाकनिष्ठं करस्य करभो बहिः ॥
ाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी ॥ ८१ ॥
ुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी ॥
ाऽनामिका चापि कनिष्ठा चेति ताः क्रमात् ॥ ८२ ॥
वः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् ॥
तालगोकर्णास्तर्जन्यादियुते तते ॥ ८३ ॥
ुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः ॥
चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ ॥ ८४ ॥
सहतौ संहतलप्रतलौ वामदक्षिणौ ॥
ार्निकुब्जः प्रसृतिस्तौ युतावञ्जलिः पुमान् ॥ ८५ ॥
ष्ठे विस्तृतकरे हस्तो मुष्ट्या तु बद्धया ॥
रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना ॥ ८६ ॥
मो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम् ॥
र्वविस्तृतदोःपाणिनृमाने पौरुषं त्रिषु ॥ ८७ ॥
ठो गलोऽथ ग्रीवायां शिरोधिः कंधरेत्यपि ॥
बुग्रीवा त्रिरेखा साऽवटुर्घाटा कृकाटिका ॥ ८८ ॥
ास्ये वदनं तुण्डमाननं लपनं मुखम् ॥
बे घ्राणं गन्धवहा घोणा नासा च नासिका ॥ ८९ ॥
ष्ठाधरौ तु रदनच्छदौ दशनवाससी ॥
धस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः ॥ ९० ॥
ना दशना दन्ता रदास्तालु तु काकुदम् ॥
ज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी ॥ ९१ ॥

ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ ॥
कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका ॥ ९२ ॥
लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी ॥
दृग्दृष्टीचास्तु नेत्राम्बु रोदनं चास्रमश्रु च ॥ ९३ ॥
अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने ॥
कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ॥ ९४
उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् ॥
चिकुरः कुन्तलो वालः कच केशः शिरोरुहः ॥ ९५
तद्वृन्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तलाः ॥
ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः ॥ ९६ ॥
कबरी केशवेशोऽथ धमिल्लः संयताः कचाः ॥
शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा ॥ ९७ ॥
वेणिः प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे ॥
पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ॥ ९८ ॥
तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुंमुखे ॥
आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ॥ ९९ ॥
दशैते त्रिष्वलंकर्ताऽलंकरिष्णुश्च मण्डितः ॥
प्रसाधितोऽलंकृतश्च भूषितश्च परिष्कृतः ॥ १०० ॥
विभ्राड् भ्राजिष्णुरोचिष्णू भूषणं स्यादलंक्रिया ॥
अलंकारस्त्वाभरणं परिष्कारो विभूषणम् ॥ १०१ ॥
मण्डनं चाथ मुकुटं किरीटं पुंनपुंसकम् ॥
चूडामणिः शिरोरत्नं तरलो हारमध्यगः ॥ १०२ ॥

लपाश्या पारितथ्या पत्रपाश्या ललाटिका ॥
र्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम् ॥ १०३ ॥
यकं कण्ठभूषा लम्बनं स्याल्ललन्तिका ॥
र्णैः प्रालम्बिकाऽथोरःसूत्रिका मौक्तिकैः कृता ॥ १०४ ॥
रो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका ॥
रभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः ॥ १०५ ॥
र्धहारो माणवक एकावल्येकयष्टिका ॥
व नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ॥ १०६ ॥
ावापकः पारिहार्यः कटको वलयोऽस्त्रियाम् ॥
यूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका ॥ १०७ ॥
ाक्षराऽङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम् ॥
ीकट्यां मेखला काञ्ची सप्तकी रशना तथा ॥ १०८ ॥
ीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु ॥
ादाङ्गुदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम् ॥ १०९ ॥
सकः पादकटकः किङ्किणी क्षुद्रघण्टिका ॥
वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु ॥ ११० ॥
ाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत् ॥
कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम् ॥ १११ ॥
अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरम् ॥
तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् ॥ ११२ ॥
पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम् ॥
क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु ॥ ११३ ॥

स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयो द्वयोः ॥
दैर्घ्यमायाम आनाहः परिणाहो विशालता ॥ ११४ ॥
पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ ॥
वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम् ॥ ११५ ॥
सुचेलकः पटोऽस्त्री स्याद्वराशिः स्थूलशाटकः ॥
निचोलः प्रच्छदपटः समौ रल्लककम्बलौ ॥ ११६ ॥
अन्तरीयोपसंव्यानपरिधानान्यधोंशुके ॥
द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ ११७ ॥
संव्यानमुत्तरीयं च चोलः कूर्पासकोऽस्त्रियाम् ॥
नीशारः स्यात्प्रावरणे हिमानिलनिवारणे ॥ ११८ ॥
अर्धोरुकं वरस्त्रीणां स्याच्चण्डातकमस्त्रियाम् ॥
स्यात्त्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् ॥ ११९ ॥
अस्त्री वितानमुल्लोचो दूष्याद्यं वस्त्रवेश्मनि ॥
प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा ॥ १२०
परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा ॥
उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः ॥ १२१ ॥
स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम् ॥
अनुबोधः पत्त्रलेखा पत्त्राङ्गुलिरिमे समे ॥ १२२ ॥
तमालपत्त्रतिलकचित्रकाणि विशेषकम् ॥
द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम् ॥ १२३ ॥
काश्मीरजन्माग्निशिखं वरं बाह्लीकपीतने ॥
रक्तसंकोचपिशुनं धीरं लोहितचन्दनम् ॥ १२४ ॥

राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः ॥
गं देवकुसुमं श्रीसंज्ञमथ जायकम् ॥ १२५ ॥
यकं च कालानुसार्यं चाथ समार्थकम् ॥
कागुरुराजार्हलोहकृमिजजोङ्गकम् ॥ १२६ ॥
गुर्वगुरु स्यात्तन्मङ्गल्या मल्लिगन्धि यत् ॥
पः सर्जरसो रालसर्वरसावपि ॥ १२७ ॥
पोऽप्यथ वृकधूपकृत्रिमधूपकौ ॥
कः पिण्डकः सिल्हो यावनोऽप्यथ पायसः ॥ १२८ ॥
सो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ ॥
भिर्मृगमदः कस्तूरी चाथ कोलकम् ॥ १२९ ॥
लकं कोशफलमथ कर्पूरमस्त्रियाम् ॥
रश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका ॥ १३० ॥
सारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् ॥
र्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥ १३१ ॥
पर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम् ॥
न्दनं चाथ जातीकोशजातीफले समे ॥ १३२ ॥
रागरुकस्तूरीकङ्कोलैर्यक्षकर्दमः ॥
नुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम् ॥ १३३ ॥
नि वासयोगाः स्युर्भावितं वासितं त्रिषु ॥
कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् ॥ १३४ ॥
यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः ॥
ष्टकं शिखालम्बि पुरो न्यस्तं ललामकम् ॥ १३५ ॥

प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षिकं तु तत् ॥
यत्तिर्यक् क्षिप्तमुरसि शिखास्वापीडशेखरौ ॥ १३६ ॥
रचना स्यात्परिस्यन्द आभोगः परिपूर्णता ॥
उपधानं तूपबर्हः शय्यायां शयनीयवत् ॥ १३७ ॥
शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः ॥
गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम् ॥ १३८
समुद्गकः संपुटकः प्रतिग्राहः पतद्ग्रहः ॥
प्रसाधनी कङ्कतिका पिष्टातः पटवासकः ॥ १३९ ॥
दर्पणे मुकुरादर्शौ व्यजनं तालवृन्तकम् ॥

॥ इति मनुष्यवर्गः ॥ ६ ॥

संततिर्गोत्रजननकुलान्यभिजनान्वयौ ॥
वंशोऽन्ववायः संतानो वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥
विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् ॥
राजबीजी राजवंश्यो बीज्यस्तु कुलसंभवः ॥ २ ॥
महाकुलकुलीनार्यसभ्यसज्जनसाधवः ॥
ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये ॥ ३ ॥
आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः ॥
विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः ॥ ४ ॥
विद्वान् विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः ॥
धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः ॥
धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ॥
दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ ॥ ६ ॥

ांसको जैमिनीये वेदान्ती ब्रह्मवादिनि ॥
क स्यादौलूक्यः सौगतः शून्यवादिनि ॥ १ ॥
कस्त्वक्षपादः स्यात्स्याद्वादिक आर्हकः ॥
कलौकायातिकौ तत्कार्यै सांख्यकापीलौ ॥ २ ॥)
ायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः ॥
याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती ॥ ७ ॥
च यजमानश्च स सोमवति दीक्षितः ॥
शिलो यायजूको यज्वा तु विधिनेष्टवान् ॥ ८ ॥
ीष्पतीष्ट्या स्थपतिः सोमपीथी तु सोमपः ॥
दाः स येनेष्टो यागः सर्वस्वदक्षिणः ॥ ९ ॥
ानः प्रवचने साङ्गेऽधीती गुरोस्तु यः ॥
ानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते ॥ १० ॥
न्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः ॥
ह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ११ ॥
र्यास्त्वेकगुरवाश्चितवानग्निमग्निचित् ॥
पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् ॥ १२ ॥
ा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः ॥
सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥ १३ ॥
होमश्चातिथीनां सपर्या तर्पणं बलिः ॥
पञ्च महायज्ञा ब्रह्मयज्ञादिनामकाः ॥ १४ ॥
या परिषद्गोष्ठी सभासमितिसंसदः ॥
थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥ १५ ॥

प्राग्वंशः प्राग्घविर्गेहात्सदस्या विधिदर्शिनः ॥
सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ॥ १
अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात् ॥
आग्नीध्राद्या धनैर्वार्या ऋत्विजोयाजकाश्च ते ॥ १७ ।
वेदिः परिष्कृता भूमिः सेम स्थण्डिलचत्वरे ॥
चषालो यूपकटकः कुम्बा सुगहना वृतिः ॥ १८ ॥
यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः ॥
दक्षिणाग्निर्गार्हपत्याहवनियौ त्रयोऽग्नयः ॥ १९ ॥
अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः ॥
समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः ॥ २० ॥
यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते ॥
तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुक्प्रिया ॥ २
ऋक् सामिधेनी धाय्या च या स्यादग्निसमिन्धने ॥
गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान् ॥ २२ ।
आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः ॥
धवित्रं व्यजनं तद्यद्रचितं मृगचर्म्मणा ॥ २३ ॥
पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम् ॥
हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम् ॥ २४
ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः ॥
उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः ॥ २५
परम्पराकं शमनं प्रोक्षणं च वधार्थकम् ॥
वाच्यलिङ्गाः प्रमीतोपसंपन्नप्रोक्षिता हते ॥ २६ ॥

यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम् ॥
ोऽवभृथो यज्ञे तत्कर्मार्हं तु यज्ञियम् ॥ २७ ॥
क्रतुकर्मेष्टं पूर्तं खातादि कर्म यत् ॥
विघसो यज्ञशेषभोजनशेषयोः ॥ २८ ॥
विहापितं दानमुत्सर्जनविसर्जने ॥
नं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥
नं निर्वपणमपवर्जनमंहतिः ॥
तदहे दानं त्रिषु स्यादौर्ध्वदैहिकम् ॥ ३० ॥
नं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः ॥
हार्यं मासिकोंऽशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम् ॥ ३१ ॥
ा परीष्टिश्चाऽन्वेषणा च गवेषणा ॥
त्वध्येषणा याच्ञाऽभिशस्तिर्याचनाऽर्थना ॥ ३२ ॥
त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि ॥
ातिथ्यातिथेये अतिथ्यर्थेऽत्र साधुनि ॥ ३३ ॥
शिक आगन्तुरतिथिर्ना गृहागते ॥
गकः प्राघुणकश्चाभ्युत्थानं तु गौरवम् ॥ ३४ ॥
नमस्याऽपचितिः सपर्याचार्हणाः समाः ॥
स्या तु शुश्रूषा परिचर्याप्युपासना ॥ ३५ ॥
ऽटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः ॥
र्शस्त्वाचमनमथ मौनमभाषणम् ॥ ३६ ॥
चेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः ॥
ोकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः ॥ ३ ॥

व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः ॥)
आनुपूर्वी स्त्रियां वाऽवृत्परिपाटी अनुक्रमः ॥
पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः ॥ ३७ ॥
नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् ॥
औपवस्तं तूपवासो विवेकः पृथगात्मता ॥ ३८ ॥
स्याद्ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिरथाञ्जलिः ॥
पाठे ब्रह्माञ्जलिः पाठे विप्रुषो ब्रह्मबिन्दवः ॥ ३९ ॥
ध्यानयोगासने ब्रह्मासनं कल्पे विधिक्रमौ ॥
मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः ॥ ४०
संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः ॥
समे तु पादग्रहणमभिवादनमित्युभे ॥ ४१ ॥
भिक्षुः परिवाट् कर्मन्दी पाराशर्यपि मस्करी ॥
तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः ॥ ४२ ॥
तपःक्लेशसहो दान्तो वर्णिनो ब्रह्मचारिणः ॥
ऋषयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती ॥ ४३ ॥
ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते ॥
यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ ॥ ४४
स्थाण्डिलश्चाथ विरजस्तमसः स्युर्द्वयातिगाः ॥
पवित्रः प्रयतः पूतः पाखण्डाः सर्वलिङ्गिनः ॥ ४५ ॥
पालाशो दण्ड आषाढो व्रते राम्भस्तु वैणवः ॥
अस्त्री कमण्डलुः कुण्डी व्रतिनामासनं वृषी ॥ ४६ ॥

ं चर्म कृत्तिः स्त्री भैक्षं भिक्षाकदम्बकम् ॥
यायः स्याज्जपः सुत्याऽभिषवः सवनं च सा ॥ ४७ ॥
सामपध्वंसि जप्यं त्रिष्वघमर्षणम् ॥
पौर्णमासश्च यागौ पक्षान्तयोः पृथक् ॥ ४८ ॥
साधनापेक्षं नित्यं यत्कर्म तद्यमः ॥
मस्तु स यत्कर्म नित्यमागन्तुसाधनम् ॥ ४९ ॥
रं तु भद्राकरणं मुण्डनं वपनं त्रिषु ॥
ीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे ॥
नावीतमन्यस्मिन्निवीतं कण्ठलम्बितम् ॥ ५० ॥
गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम् ॥
ऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले त्वङ्गुष्ठस्य ब्राह्मम् ॥ ५१ ॥
ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥
ूयादिकं तद्वत्कृच्छ्रं सांतपनादिकम् ॥ ५२ ॥
ासवत्यनशने पुमान्प्रायोऽथ वीरहा ॥
ग्निः कुहना लोभान्मिथ्येर्यापथकल्पना ॥ ५३ ॥
यः संस्कारहीनः स्यादस्वाध्यायो निराकृतिः ॥
ध्वजी लिङ्गवृत्तिरवकीर्णी क्षतव्रतः ॥ ५४ ॥
यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ॥
ुमानाभिनिर्मुक्ताभ्युदितौ च यथाक्रमम् ॥ ५५ ॥
वेत्ताऽनुजोऽनूढे ज्येष्ठे दारपरिग्रहात् ॥
वित्तिस्तु तज्ज्यायान् विवाहोपयमौ समौ ॥ ५६ ॥

WORLD

तथा परिणयोद्वाहोपयामाः पाणिपीडनम् ॥
व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् ॥ ५७ ॥
त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः ॥
सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये ॥ ५८ ॥

॥ इति ब्रह्मवर्गः ॥ ७ ॥

मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् ॥
राज्ञि राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ॥ १ ॥
राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः ॥
चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः ॥ २ ॥
येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ॥
शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥ ३ ॥
राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् ॥
मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः ॥ ४ ॥
महामात्राः प्रधानानि पुरोधास्तु पुरोहितः ॥
द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ ॥ ५ ॥
प्रतीहारो द्वारपालद्वाःस्थद्वाःस्थितदर्शकाः ॥
रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ ॥ ६ ॥
स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु ॥
भौरिकः कनकाध्यक्षो रूपाध्यक्षस्तु नैष्किकः ॥ ७ ॥
अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः ॥
सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ॥ ८

ा वर्षवरस्तुल्यो सेवकार्थ्यनुजीविनः ॥
यानन्तरो राजा शत्रुर्मित्रमतः परम् ॥ ९ ॥
सीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः ॥
ौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः ॥ १० ॥
ड्विपक्षाहितामित्रदस्युशात्रवशत्रवः ॥
भिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥
स्यः स्निग्धः सवया अथ मित्रं सखा सुहृत् ॥
ख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम् ॥ १२ ॥
ार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः ॥
श्च गूढपुरु[illegible]प्रत्ययितौ समौ ॥ १३ ॥
वत्सरो ज्योतिषिको दैवज्ञगणकावपि ॥
ुर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि ॥ १४ ॥
न्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ ॥
पिकरोऽक्षरचणोऽक्षरचञ्चुश्च लेखके ॥ १५ ॥
खिताक्षरविन्यासे लिपिर्लिबिरुभे स्त्रियौ ॥
ात्संदेशहरो दूतो दूत्यं तद्भावकर्मणी ॥ १६ ॥
ध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि ॥
ाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ॥ १७ ॥
ज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥
धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ॥ १८ ॥
ड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः ॥
यः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥ १९ ॥

स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् ॥
सामदाने भेददण्डावित्युपायचतुष्टयम् ॥ २० ॥
साहसं तु दमो दण्डः साम सान्त्वमथो समौ ॥
भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम् ॥ २१ ॥
पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः ॥
विविक्तविजनच्छन्ननिःशलाकास्तथा रहः ॥ २२ ॥
रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु ॥
समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात् ॥ २३ ॥
अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम् ॥
युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ॥ २४ ॥
न्याय्यं च त्रिषु षट् संप्रधारणा तु समर्थनम् ॥
अववादस्तु निर्देशो निदेशः शासनं च सः ॥ २५ ॥
शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः ॥
आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने ॥ २६ ॥
द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः ॥
घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम् ॥ २७ ॥
उपायनमुपग्राह्यमुपहारस्तथोपदा ॥
यौतकादि तु यद्देयं सुदायो हरणं च तत् ॥ २८ ॥
तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः ॥
सांदृष्टिकं फलं सद्य उदर्कः फलमुत्तरम् ॥ २९ ॥
अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् ॥
महीभुजामहिभयं स्वपक्षप्रभवं भयम् ॥ ३० ॥

क्या त्वधिकारः स्याच्चामरं तु प्रकीर्णकम् ॥
ासनं यत्तद्भद्रासनं सिंहासनं तु तत् ॥ ३१ ॥
छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत् ॥
कुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका ॥ ३२ ॥
वेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम् ॥
त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ३३ ॥
ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः ॥
ङ्गजो गजो नागः कुञ्जरो वारणः करी ॥ ३४ ॥
ः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः ॥
ोत्कटो मदकलः कलभः करिशावकः ॥ ३५ ॥
भिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ ॥
ास्तिकं गजता वृन्दे करिणी धेनुका वशा ॥ ३६ ॥
ण्डः कटो मदो दानं वमथुः करशीकरः ॥
म्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान् ॥ ३७ ॥
वग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम् ॥
पाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका ॥ ३८ ॥
धः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत् ॥
आसनं स्कन्धदेशः स्यात्पद्मकं बिन्दुजालकम् ॥ ३९ ॥
ार्श्वभागः पक्षभागो दन्तभागस्तु योऽग्रतः ॥
ौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात् ॥ ४० ॥
तोत्रं वैणुकमालानं बन्धस्तम्भेऽथ शृङ्खला ॥
अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम् ॥ ४१ ॥

दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे ॥
प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः ॥ ४२ ॥
वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी ॥
घोटके वीतितुरगतुरंगाश्वतुरंगमाः ॥ ४३ ॥
वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः ॥
आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः ॥ ४४ ॥
वनायुजाः पारसीकाः काम्बोजाः बाह्लिका हयाः ॥
ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिकः ॥ ४५ ॥
पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः ॥
बालः किशोरो वाम्यश्वा वडवा वाडवं गणे ॥ ४६ ॥
त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते ॥
कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निःस्वनः ॥ ४७ ॥
निगालस्तु गलोद्देशो वृन्दे त्वश्वीयमाश्ववत् ॥
आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् ॥ ४८ ॥
गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम् ॥
कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान् ॥ ४९ ॥
पुच्छोऽस्त्री लूमलाङ्गूले वालहस्तश्च वालधिः ॥
त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ॥ ५० ॥
याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः ॥
असौ पुष्यरथश्चक्रयानं न समराय यत् ॥ ५१ ॥
कर्णीरथः प्रवहणं डयनं च समं त्रयम् ॥
क्लीबेऽनः शकटोऽस्त्री स्याद्गन्त्री कम्बलिवाह्यकम् ॥ ५२ ॥

ाबिका याप्ययानं स्याद्दोला प्रेङ्खादिका स्त्रियाम् ।।
भौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे ।। ५३ ।।
ण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली ।।
थे काम्बलवास्त्राद्याः कम्बलादिभिरावृते ।। ५४ ।।
षु द्वैपादयो रथ्या रथकट्या रथव्रजे ।।
ः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः ।। ५५ ।।
क्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् ।।
ण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः ।। ५६ ।।
थगुप्तिर्वरूथो ना कूबरस्तु युगंधरः ।।
नुकर्षो दार्वधःस्थं प्रासङ्गो ना युगान्तरम् ।। ५७ ।।
र्वं स्याद्वाहनं यानं युग्यं पत्त्रं च धोरणम् ।।
रम्परावाहनं यत्तद्वैनीतकमस्त्रियाम् ।। ५८ ।।
आधोरणा हस्तिपका हस्त्यारोहा निषादिनः ।।
नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः ।। ५९ ।।
सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः ।।
रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः ।। ६० ।।
भटा योधाश्च योद्धारः सेनारक्षास्तु सैनिकाः ।।
सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते ।। ६१ ।।
बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः ।।
परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः ।। ६२ ।।
कञ्चुको वारबाणोऽस्त्री यत्तु मध्ये सकञ्चुकाः ।।
बध्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम् ।। ६३ ।।

शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् ॥
उरच्छदः कङ्कटको जगरः कवचोऽस्त्रियाम् ॥६४॥
आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ॥
संनद्धो वर्मितः सज्जो दंशितो व्यूढकङ्कटः ॥ ६५ ॥
त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे ॥
पदातिपत्तिपदगपादातिकपदाजयः ॥ ६६ ॥
पद्गश्च पदिकश्चाऽथ पादातं पत्तिसंहतिः ॥
शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः ॥ ६७ ॥
कृतहस्तः सुप्रयोगविशिखः कृतपुङ्खवत् ॥
अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः ॥ ६८ ॥
धन्वी धनुष्मान्धानुष्को निषङ्ग्यस्त्री धनुर्धरः
स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः ॥ ६९ ॥
याष्टीकपारश्वधिकौ यष्टिपार्श्वधहेतिकौ ॥
नैस्त्रिंशिकोऽसिहेतिः स्यात्समौ प्रासिककौन्तिकौ ॥ ७० ॥
चर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः ॥
अनुप्लवः सहायश्चाऽनुचरोऽभिचरः समाः ॥ ७१ ॥
पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः ॥
पुरोगमः पुरोगामी मन्दगामी तु मन्थरः ॥ ७२ ॥
जङ्घालोऽतिजवस्तुल्यौ जङ्घाकारिकजाङ्घिकौ ॥
तरस्वी त्वरितो वेगी प्रजवी जवनो जवः ॥ ७३ ॥
जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके ॥
जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति ॥ ७४ ॥

भ्यमित्र्योऽभ्यमित्रीयोप्यभ्यमित्रीण इत्यपि ॥
स्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः ॥ ७५ ॥
उरस्वानुरसिलो रथिनो रथिनो रथी ॥
गाम्यनुकामीनो ह्यत्यन्तीनस्तथा भृशम् ॥ ७६ ॥
वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः ॥
गीनो रणे साधुः शस्त्राजीवादयस्त्रिषु ॥ ७७ ॥
नी वाहिनी सेना पृतनाऽनीकिनी चमूः ॥
थनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ॥ ७८ ॥
स्तु बलविन्यासो भेदा दण्डादयो युधि ॥
सारो व्यूहपार्ष्णिः सैन्यपृष्ठे प्रतिग्रहः ॥ ७९ ॥
भकरथा त्र्यश्वा पत्तिः पञ्च पदातिका ॥
ङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥
मुखं गुल्मगणौ वाहिनी पृतना चमूः ॥
किनी दशानीकिन्यक्षौहिण्यथ संपदि ॥ ८१ ॥
त्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ ॥
ुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ ॥ ८२ ॥
श्चापौ धन्वशरासनकोदण्डकार्मुकम् ॥
सोऽप्यथ कर्णस्य कालपृष्ठं शरासनम् ॥ ८३ ॥
ध्वजस्य गाण्डीवगाण्डिवौ पुंनपुंसकौ ॥
टिरस्याटनी गोधातले ज्याघातवारणे ॥ ८४ ॥
तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः ॥
त्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् ॥ ८५ ॥

लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम् ॥
पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ॥ ८६ ॥
कलम्बमार्गणशराः पत्त्री रोप इषुर्द्वयोः ॥
प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे ॥ ८७ ॥
निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ ॥
तूणोपासंगतूणीरनिषंगा इषुधिर्द्वयोः ॥ ८८ ॥
तूण्यां खड्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः ॥
कौक्षेयको मण्डलाग्रः करवालः कृपाणवत् ॥ ८९ ॥
त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम् ॥
फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः ॥ ९० ॥
द्रुघणो मुद्गरघनौ स्यादीली करवालिका ॥
भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः ॥ ९१ ॥
द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः ॥
स्याच्छस्त्री चासिपुत्री च छुरिका चासिधनुका ॥ ९
वा पुंसि शल्यं शङ्कुर्ना शर्वला तोमरोऽस्त्रियाम् ॥
प्रासस्तु कुन्तः कोणस्तु स्त्रियः पाल्यश्रिकोटयः ॥ ९
सर्वाभिसारः सर्वौघः सर्वसंनहनार्थकः ॥
लोहाभिसारोऽस्त्रभृतां राज्ञां निराजनाविधिः ॥ ९४ ॥
यत्सेनयाभिगमनमरौ तदभिषेणनम् ॥
यात्रा व्रज्याऽभिनिर्याणं प्रस्थानं गमनं गमः ॥ ९५ ॥
स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम् ॥
अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः ॥ ९६ ॥

लिका बोधकराश्चाक्रिका घाण्टिकाऽर्थकाः ॥
ागधास्तु मगधा बन्दिनः स्तुतिपाठकाः ॥ ९७ ॥
कास्तु समायात्सङ्ग्रामादनिवर्तिनः ॥
योः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः ॥ ९८ ॥
क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले ॥
का वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ॥ ९९ ॥
ीराशंसनं युद्धभूमिर्याऽतिभयप्रदा ॥
पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियाम् ॥ १०० ॥
पुरुषिका दर्पाद्या स्यात्संभावनात्मनि ॥
हामिका तु सा स्यात्परस्परं यो भवत्यहंकारः ॥ १०१ ॥
णं तरः सहोबलशौर्याणि स्थाम शुष्मं च ॥
ः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता ॥ १०२ ॥
ाणं तु यत्पानं वृत्ते भाविनि वा रणे ॥
ायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३ ॥
ास्कन्दनं संख्यं समीकं सांपरायिकम् ॥
यां समरानीकरणाः कलहविग्रहौ ॥ १०४ ॥
ाराभिसंपातकलिसंस्फोटसंयुगाः ॥
ामर्दसमाघातसङ्ग्रामाभ्यागमाहवाः ॥ १०५ ॥
ायः स्त्रियः संयत्समित्याजिसमिद्युधः ॥
द्धं बाहुयुद्धेऽथ तुमुलं रणसंकुले ॥ १०६ ॥
ा तु सिंहनादः स्यात्करिणां घटना घटा ॥
नं योधसंरावो बृंहितं करिगर्जितम् ॥ १०७ ॥
फारो धनुषः स्वानः पटहाडम्बरौ समौ ॥

प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम् ॥ १०८ ॥
अजन्यं क्लीबमुत्पात उपसर्गः समं त्रयम् ॥
मूर्च्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम् ॥ १०९ ॥
अभ्यवस्कन्दनं त्वभ्यासादनं विजयो जयः ॥
वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा ॥ ११० ॥
प्रद्रावोद्रावसंद्रावसंदावा विद्रवो द्रवः ॥
अपक्रमोऽपयानं च रणे भङ्गः पराजयः ॥ १११ ॥
पराजितपराभूतौ त्रिषु नष्टतिरोहितौ ॥
प्रमापणं निबर्हणं निकारणं विशारणम् ॥ ११२ ॥
प्रवासनं परासनं निषूदनं निहिंसनम् ॥
निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम् ॥ ११३ ॥
निस्तर्हणं निहननं क्षणनं परिवर्जनम् ॥
निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४ ॥
उद्वासनप्रमथनक्रथनोज्जासनानि च ॥
आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ ११५ ॥
स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः ॥
अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ॥ ११६ ॥
परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः ॥
मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम् ॥ १
कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम् ॥
श्मशानं स्यात्पितृवनं कुणपः शवमस्त्रियाम् ॥ ११८ ॥

होपग्रहौ बन्द्यां कारा स्याद्बन्धनालये ॥
ा भूम्न्यसवः प्राणाश्चैवं जीवोऽसुधारणम् ॥ ११९ ॥
युर्जीवितकालो ना जीवातुर्जीवनौषधम् ॥

इति क्षत्रियवर्गः ॥ ८ ॥

व्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः ॥
जीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥ १ ॥
यां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः ॥
ा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम् ॥ २ ॥
याचितायाचितयोर्यथासंख्यं मृतामृते ॥
यानृतं वणिग्भावः स्यादृणं पर्युदञ्चनम् ॥ ३ ॥
ारोऽर्थप्रयोगस्तु कुसीदं वृद्धिजीविका ॥
ञयाप्तं याचितकं निमयादापमित्यकम् ॥ ४ ॥
मर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात् ॥
ीदिको वार्धुषिको वृद्ध्याजीवश्च वार्धुषिः ॥ ५ ॥
ाजीवः कर्षकश्च कृषिकश्च कृषीवलः ॥
ं व्रैहेयशालेयं व्रीहिशाल्युद्भवोचितम् ॥ ६ ॥
यं यवक्यं षष्टिक्यं यवादिभवनं हि यत् ॥
ल्यं तैलीनवन्माषोमाणुभङ्गा द्विरूपता ॥ ७ ॥
द्गीनकौद्रवीणादिशेषधान्योद्भवक्षमम् ॥
ाकक्षेत्रादिके शाकशाकटं शाकशाकिनम् ॥)
ाकृतं तूप्तकृष्टे सीत्यं कृष्टं च हल्यवत् ॥ ८ ॥

त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् ॥
द्विगुणाकृते तु सर्वं पूर्वं शम्बाकृतमपीह ॥ ९ ॥
द्रोणाढकादिवापादौ द्रौणिकाढकिकादयः ॥
खारीवापस्तु खारीक उत्तमर्णादयस्त्रिषु ॥ १० ॥
पुंनपुंसकयोर्वप्रः केदारः क्षेत्रमस्य तु ॥
कैदारकं स्यात्कैदार्यं क्षेत्रं कैदारिकं गणे ॥ ११ ॥
लोष्टानि लेष्टवः पुंसि कोटिशो लोष्टभेदनः ॥
प्राजनं तोदनं तोत्रं खनित्रमवदारणे ॥ १२ ॥
दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम् ॥
निरीशं कुटकं फालः कृषको लाङ्गलं हलम् ॥ १३ ॥
गोदारणं च सीरोऽथ शम्या स्त्री युगकीलकः ॥
ईषा लाङ्गलदण्डः स्यात्सीता लाङ्गलपद्धतिः ॥ १४ ॥
पुंसि मेधिः खले दारु न्यस्तं यत्पशुबन्धने ॥
आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ ॥ १५ ॥
तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः ॥
हरेणुरेणुकौ चास्मिन्कोरदूषस्तु कोद्रवः ॥ १६ ॥
मङ्गल्यको मसूरोऽथ मकुष्टकमयुष्टकौ ॥
वनमुद्गे सर्षपे तु द्वौ तन्तुभकदम्बकौ ॥ १७ ॥
सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ ॥
स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः ॥ १८ ॥
द्वौ तिले तिलपेजश्च तिलपिञ्जश्च निष्फले ॥
क्षवः क्षुताभिजननो राजिका कृष्णिकाऽऽसुरी ॥ १९ ॥

ौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा ॥
लानी तु भङ्गायां व्रीहिभेदस्त्वणुः पुमान् ॥ २० ॥
ारुः सस्यशूकं स्यात्कणिशं सस्यमञ्जरी ॥
यं व्रीहिःस्तम्बकरिःस्तम्बो गुच्छस्तृणादिनः ॥ २१ ॥
ी नालं च काण्डोऽस्य पलालोऽस्त्री स निष्फलः ॥
ङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान् ॥ २२ ॥
ोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे ॥
द्मावासितं धान्यं पूतं तु बहुलीकृतम् ॥ २३ ॥
ादयः शमीधान्ये शूकधान्ये यवादयः ॥
लयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी ॥ २४ ॥
धान्यानि नीवाराः स्त्री गवेधुर्गवेधुका ॥
ाग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम् ॥ २५ ॥
फोटनं शूर्पमस्त्री चालनी तितउः पुमान् ॥
तप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ ॥ २६ ॥
ानौ रसवत्यां तु पाकस्थानमहानसे ॥
ोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः ॥ २७ ॥
रालिका आन्धसिकाः सूदा औदनिका गुणाः ॥
पूपिकः कान्दविको भक्ष्यकार इमे त्रिषु ॥ २८ ॥
मन्तमुद्धानमाधिश्रयणी चुल्लिरन्तिका ॥
ङ्गारधानिकाऽङ्गारशकट्यपि हसन्त्यपि ॥ २९ ॥
न्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् ॥
विऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम् ॥ ३० ॥

अलञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका ॥
पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः ॥ ३१ ॥
घटः कुटनिपावस्त्री शरावो वर्धमानकः ॥
ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम् ॥ ३२ ॥
कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् ॥
सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम् ॥ ३३ ॥
दर्विः कम्बिः खजाका च स्यात्तर्दूर्दारुहस्तकः ॥
अस्त्री शाकं हरितकं शिग्रुरस्य तु नाडिका ॥ ३४ ॥
कलम्बश्च कडम्बश्च वेसवार उपस्करः ॥
तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम् ॥ ३५ ॥
मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम् ॥
जीरको जरणोऽजाजी कणा कृष्णे तु जीरके ॥ ३६ ॥
सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्चिका ॥
आर्द्रकं शृङ्गवेरं स्यादथ छत्रा वितुन्नकम् ॥ ३७ ॥
कुस्तुम्बुरु च धान्याकमथ शुण्ठी महौषधम् ॥
स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥ ३८ ॥
आरनालकसौवीरकुल्माषाभिषुतानि च ॥
अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके ॥ ३९ ॥
सहस्रवेधि जतुकं बाह्लीकं हिङ्गु रामठम् ॥
तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः ॥ ४० ॥
निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी ॥
सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत् ॥ ४१ ॥

न्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे ॥
मकं वसुकं पाक्यं बिडं च कृतके द्वयम् ॥ ४२ ॥
वर्चलेऽक्षरुचके तिलकं तत्र मेचके ॥
त्स्यण्डी फाणितं खण्डविकारः शर्करा सिता ॥ ४३ ॥
र्चिका क्षीरविकृतिः स्याद्रसाला तु मार्जिता ॥
यात्तेमनं तु निष्ठानं त्रिलिङ्गा वासितावधेः ॥ ४४ ॥
लाकृतं भटित्रं स्याच्छूल्यमुख्यं तु पैठरम् ॥
णीतमुपसंपन्नं प्रयस्तं स्यात्सुसंस्कृतम् ॥ ४५ ॥
यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे ॥
क्कणं मसृणं स्निग्धं तुल्ये भावितवासिते ॥ ४६ ॥
पक्वं पौलिरभ्यूषो लाजाः पुंभूम्नि चाक्षताः ॥
थुकः स्याच्चिपिटको धाना भ्रष्टयवे स्त्रियः ॥ ४७ ॥
पोऽपूपः पिष्टकः स्यात्करम्भो दधिसक्तवः ॥
भिस्सास्त्रीभक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः ॥ ४८ ॥
भिस्सटा दग्धिका सर्वरसाग्रे मण्डमस्त्रियाम् ॥
सराचामनिस्रावा मण्डे भक्तसमुद्भवे ॥ ४९ ॥
वागूरुष्णिका श्राणा विलेपी तरला च सा ॥
म्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदनः ॥ १ ॥)
व्यं त्रिषु गवां सर्वं गोविद् गोमयमस्त्रियाम् ॥ ५० ॥
त्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयः समम् ॥
यस्यमाज्यदध्यादि द्रप्सं दधि घनेतरत् ॥ ५१ ॥

घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्धृतम् ॥
तत्तु हैयंगवीनं यत् ह्योगोदोहोद्भवं घृतम् ॥ ५२ ॥
दण्डाहतं कालशेयमरिष्टमपि गोरसः ॥
तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् ॥ ५३ ॥
मण्डं दधिभवं मस्तु पीयूषोऽभिनवं पयः ॥
अशनाया बुभुक्षा क्षुद्ग्रासस्तु कवलः पुमान् ॥ ५४ ॥
सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम् ॥
उदन्या तु पिपासा तृट् तर्षो जग्धिस्तु भोजनम् ॥ ५५
जेमनं लेह आहारो निघासो न्याद इत्यपि ॥
सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम् ॥ ५६ ॥
कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् ॥
गोपे गोपालगोसंख्यगोधुगाभीरबल्लवाः ॥ ५७ ॥
गोमाहिष्यादिकं पादबन्धनं द्वौ गवीश्वरे ॥
गोमान्गोमी गोकुलं तु गोधनं स्याद्गवां व्रजे ॥ ५८ ॥
त्रिष्वाशितं गवीनं तद्गावो यत्राशिताः पुरा ॥
उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः ॥ ५९ ॥
अनड्वान्सौरभेयो गौरुक्ष्णां संहतिरौक्षकम् ॥
गव्या गोत्रा गवां वत्सधेन्वोर्वात्सकधैनुके ॥ ६० ॥
वृषो महान्महोक्षः स्याद्वृद्धोक्षस्तु जरद्गवः ॥
उत्पन्न उक्षा जातोक्षः सद्यो जातस्तु तर्णकः ॥ ६१ ॥
शकृत्करिस्तु वत्सः स्याद्दम्यवत्सतरौ समौ ॥
आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः ॥ ६२ ॥

देशे त्वस्य वहः सास्ना तु गलकम्बलः ॥
स्तितस्तु नस्योतः प्रष्ठवाड् युगपार्श्वगः ॥ ६३ ॥
दीनां तु वोढारो युग्यप्रासङ्ग्यशाकटाः ॥
ति तेन तद्वोढाऽस्येदं हालिकसैरिकौ ॥ ६४ ॥
धुर्यधौरेयधुरीणाः सधुरंधराः ॥
वेकधुरीणैकधुरावेकधुरावहे ॥ ६५ ॥
सर्वधुरीणः स्याद्यो वै सर्वधुरावहः ॥
यी सौरभेयी गौरुस्रा माता च शृङ्गिणी ॥ ६६ ॥
न्यघ्न्या रोहिणी स्यादुत्तमा गोषु नैचिकी ॥
दिभेदात्संज्ञाः स्युः शबलीधवलादयः ॥ ६७ ॥
यनी द्विवर्षा गौरेकाब्दा त्वेकहायनी ॥
रब्दा चतुर्हायण्येवं त्र्यब्दा त्रिहायणी ॥ ६८ ॥
वन्ध्याऽवतोका तु स्रवद्गर्भाऽथ संधिनी ॥
क्रान्ता वृषभेणाथ वेहद्गर्भोपघातिनी ॥ ६९ ॥
ल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी ॥
दचण्डी तु सुकरा बहुसूतिः परेष्टुका ॥ ७० ॥
प्रसूता बष्कायिणी धेनुः स्यान्नवसूतिका ॥
ता सुखसंदोह्या पीनोध्नी पीवरस्तनी ॥ ७१ ॥
क्षीरा द्रोणदुग्धा धेनुष्या बन्धके स्थिता ॥
समीना सा यैव प्रतिवर्षं प्रसूयते ॥ ७२ ॥
धस्तु क्लीबमापीनं समौ शिवककीलकौ ॥
पुंसि दाम संदानं पशुरज्जुस्तु दामनी ॥ ७३ ॥

वैशाखमन्थमन्थानमन्थानो मन्थदण्डके ॥
कुठरो दण्डविष्कम्भौ मन्थनी गर्गरी समे ॥ ७४ ॥
उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः ॥
करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः ॥ ७५ ॥
अजा छागी शुभच्छागबस्तच्छगलका अजे ॥
मेढ्रोरभ्रोरणोर्णायुमेषवृष्णय एडके ॥ ७६ ॥
उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम् ॥
चक्रीवन्तस्तु बालेया रासभा गर्दभाः खराः ॥ ७७ ॥
वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् ॥
पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ॥ ७८ ॥
विक्रेता स्याद्विक्रयिकः क्रायिकक्रयिकौ समौ ॥
वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः ॥ ७९
नीवी परिपणो मूलधनं लाभोऽधिकं फलम् ॥
परिदानं परीवर्तो नैमेयनिमयावपि ॥ ८० ॥
पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम् ॥
क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके ॥ ८१ ॥
विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु ॥
क्लीबे सत्यापनं सत्यंकारः सत्याकृतिः स्त्रियाम् ॥ ८२
विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु ॥
विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः ॥ ८३ ॥
संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ॥
पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरम् ॥ ८४ ॥

वं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ॥
ं तुलाऽङ्गुलिप्रस्थैर्गुञ्जाः पञ्चाद्यमाषकः ॥ ८५ ॥
ोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् ॥
र्णबिस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८६ ॥
ा स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः ॥
चितो दश भाराः स्युः शाकटो भार आचितः ॥ ८७ ॥
र्षापणः कार्षिकः स्यात्कार्षिके ताम्रिके पणः ॥
स्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः ॥ ८८ ॥
वः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ॥
स्तुरीयो भागः स्यादंशभागौ तु वण्टके ॥ ८९ ॥
थं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ॥
ण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ॥ ९० ॥
त्कोषश्च हिरण्यं च हेमरूप्ये कृताकृते ॥
भ्यां यदन्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम् ॥ ९१ ॥
रुत्मतं मरकतमश्मगर्भो हरिन्मणिः ॥
णरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम् ॥ ९२ ॥
क्ताऽथ विद्रुमः पुंसि प्रवालं पुंनपुंसकम् ॥
नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च ॥ ९३ ॥
र्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् ॥
नीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम् ॥ ९४ ॥
मीकरं जातरूपं महारजतकाञ्चने ॥
मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम ॥ ९५ ॥

अलंकारसुवर्णं यच्छृङ्गीकनकमित्यदः ॥
दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि ॥ ९६ ॥
रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् ॥
शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्ठोदुम्बराणि च ॥ ९७ ॥
लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी ॥
अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले ॥ ९८ ॥
सर्वं च तैजसं लोहं विकारस्त्वयसः कुशी ॥
क्षारः काचोऽथ चपलो रसः सूतश्च पारदे ॥ ९९ ॥
गवलं माहिषं शृङ्गमभ्रकं गिरिजामले ॥
स्रोतोञ्जनं तु सौवीरं कापोताञ्जनयामुने ॥ १०० ॥
तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके ॥
कर्परी दार्विकाक्वाथोद्भवं तुत्थं रसाञ्जनम् ॥ १०१ ॥
रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धकः ॥
सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका ॥ १०२ ॥
रीतिपुष्पं पुष्पकेतु पौष्पकं कुसुमाञ्जनम् ॥
पिञ्जरं पीतनं तालमालं च हरितालके ॥ १०३ ॥
गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु ॥
बोलगन्धरसप्राणपिण्डगोपरसाः समाः ॥ १०४ ॥
डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम् ॥
नागसीसकयोगेष्टवप्राणि त्रपु पिच्चटम् ॥ १०५ ॥
रङ्गवङ्गे अथ पिचुस्तूलोऽथ कमलोत्तरम् ॥
स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि ॥ १०६ ॥

कम्बल ऊणायुः शशोर्णं शशलोमनि ॥
क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम् ॥ १०७ ॥
ःशिला मनोगुप्ता मनोह्वा नागजिह्विका ॥
ली कुनटी गोला यवक्षारो यवाग्रजः ॥ १०८ ॥
योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः ॥
र्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना ॥ १०९ ॥
ुजं श्वेतमरिचं मोरटं मूलमैक्षवम् ॥
थकं पिप्पलीमूलं चटिकाशिर इत्यपि ॥ ११० ॥
ोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम् ॥
कटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम् ॥ १११ ॥

॥ इति वैश्यवर्गः ॥ ९ ॥

श्चावरवर्णाश्च वृषलाश्च जघन्यजाः ॥
चण्डालात्तु संकीर्णा अम्बष्ठकरणादयः ॥ १ ॥
ाविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः ॥
ाक्षत्त्रिययोरुग्रो मागधः क्षत्त्रियाविशोः ॥ २ ॥
ष्योर्याक्षत्त्रिययोः क्षत्ताऽर्याशूद्रयोः सुतः ॥
ण्यां क्षत्त्रियात्सूतस्तस्यां वैदेहको विशः ॥ ३ ॥
कारस्तु माहिष्यात्करण्यां यस्य संभवः ॥
च्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः ॥ ४ ॥
ः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः ॥
कः स्यात्कुलश्रेष्ठी मालाकारस्तु मालिकः ॥ ५ ॥

कुम्भकारः कुलालः स्यात्पलगण्डस्तु लेपकः ॥
तन्तुवायः कुविन्दः स्यात्तुन्नवायस्तु सौचिकः ॥ ६ ॥
रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसिधाकः ॥
पादूकृच्चर्मकारः स्याद्व्योकारो लोहकारकः ॥ ७ ॥
नाडिंधमः स्वर्णकारः कलादो रुक्मकारकः ॥
स्याच्छाङ्खिकः काम्बविकः शौल्बिकस्ताम्रकुट्टकः ॥ ८
तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट् ॥
ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः ॥ ९ ॥
क्षुरी मुण्डी दिवाकीर्तिनापितान्तावसायिनः ॥
निर्णेजकः स्याद्रजकः शौण्डिको मण्डहारकः ॥ १० ॥
जाबालः स्यादजाजीवो देवाजीवस्तु देवलः ॥
स्यान्माया शाम्बरी मायाकारस्तु प्रातिहारिकः ॥ ११
शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः ॥
भरता इत्यपि नटाश्चारणास्तु कुशीलवाः ॥ १२ ॥
मार्दङ्गिका मौरजिकाः पाणिवादास्तु पाणिघाः ॥
वेणुध्माः स्युर्वैणविका वीणावादास्तु वैणिकाः ॥ १३ ॥
जीवान्तकः शाकुनिको द्वौ वागुरिकजालिकौ ॥
वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम् ॥ १४ ॥
भृतको भृतिभुक् कर्मकरो वैतानिकोऽपि सः ॥
वार्तावहो वैवधिको भारवाहस्तु भारिकः ॥ १५ ॥
विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः ॥
निहीनोऽपसदो जाल्मःक्षुल्लकश्चेतरश्च सः ॥ १६ ॥

१०९५

दासेरदासेयदासगोप्यकचेटकाः ॥
यकिंकरप्रैष्यभुजिष्यपरिचारकाः ॥ १७ ॥
तपरिस्कन्दपरजातपरैधिताः ॥
ुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः ॥ १८ ॥
ु चतुरपेशलपटवः सूत्थान उष्णश्च ॥
प्लवमातङ्गदिवाकीर्तिजनंगमाः ॥ १९ ॥
श्वपचावन्तेवासिचाण्डालपुक्कसाः ॥
किरातशबरपुलिन्दा म्लेच्छजातयः ॥ २० ॥
मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः ॥
कः सारमेयः कुक्कुरो मृगदंशकः ॥ २१ ॥
भषकः श्वा स्यादलर्कस्तु स योगितः ॥
विश्वकद्रुर्मृगयाकुशलः सरमा शुनी ॥ २२ ॥
रः सूकरो ग्राम्यो वर्करस्तरुणः पशुः ॥
छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् ॥ २३ ॥
ारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः ॥
ागारिकस्तेनदस्युतस्करमोषकाः ॥ २४ ॥
ोधिपरास्कन्दिपाटच्चरमलिम्लुचाः ॥
का स्तैन्यचौर्ये च स्तेयं लोप्त्रं तु तद्धने ॥ २५ ॥
स्तूपकरणं बन्धने मृगपक्षिणाम् ॥
थः कूटयन्त्रं स्याद्वागुरा मृगबन्धनी ॥ २६ ॥
वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः ॥
नं घटीयन्त्रं सलिलोद्वाहनं प्रहेः ॥ २७ ॥

पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः ॥
वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि ॥ २८ ॥
पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता ॥
जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु ॥ २९ ॥
पिटकः पेटकः पेटा मञ्जूषाऽथ विहङ्गिका ॥
भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका ॥ ३० ॥
पादूरुपानत्स्त्री सैवानुपदीना पदायता ॥
नद्ध्री वध्री वरत्रा स्यादश्वादेस्ताडनी कशा ॥ ३१ ॥
चाण्डालिका तु कण्डोलवीणा चण्डालवल्लकी ॥
नाराची स्यादेषणिका शाणस्तु निकषः कषः ॥ ३२ ॥
व्रश्चनः पत्रपरशुरीतूषिका लिका समे ॥
तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका ॥ ३३ ॥
आस्फोटनी वेधनिका कृपाणी कर्तरी समे ॥
वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः ॥ ३४ ॥
क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेदिका ॥
सूर्मी स्थूणाऽयःप्रतिमा शिल्पं कर्म कलादिकम् ॥ ३५
प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया ॥
प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ॥ ३६
वाच्यालिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ॥
साधारणः समानश्च स्युरुत्तरपदे त्वमी ॥ ३७ ॥
निभसंकाशनीकाशप्रतीकाशोपमादयः ॥
कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् ॥ ३८ ।

ं भरणं मूल्यं निर्वेशः पण इत्यपि ॥
हालिप्रिया हाला परिस्रुद्वरुणात्मजा ॥ ३९ ॥
त्तमाप्रसन्नेराकादम्बर्यः परिस्रुता ॥
ा कश्यमद्ये चाप्यवदंशस्तु भक्षणम् ॥ ४० ॥
ापानं मदस्थानं मधुवारा मधुक्रमाः ॥
ासवो माधवको मधु माध्वीकमद्वयोः ॥ ४१ ॥
मासवः सीधुर्मेदको जगलः समौ ॥
नं स्यादभिषवः किण्वं पुंसि तु नग्नहूः ॥ ४२ ॥
त्तरः सुरामण्ड आपानं पानगोष्ठिका ॥
कोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम् ॥ ४३ ॥
ऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः ॥
ग्नकाः प्रतिभुवः सभिका द्यूतकारकाः ॥ ४४ ॥
ऽस्त्रियामक्षवती कैतवं पण इत्यपि ॥
ऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते ॥ ४५ ॥
गायस्तु शारीणां समन्तान्नयनेऽस्त्रियाम् ॥
पदं शारिफलं प्राणिद्यूतं समाह्वयः ॥ ४६ ॥
ा भूरिप्रयोगत्वादेकस्मिन्येऽत्र यौगिकाः ॥
र्म्यादन्यतो वृत्तावूह्या लिङ्गान्तरेऽपि ते ॥ ४७ ॥

॥ इति शूद्रवर्गः ॥ १० ॥

मरसिंहकृतौ नामलिङ्गानुशासने ॥
यकाण्डो भूम्यादिः साङ्ग एव समर्थितः ॥ १ ॥
रसिंहकृतौ नामलिङ्गानुशासने द्वितीयं काण्डं समाप्तम् ॥

तृतीयं काण्डम् ।

विशेष्यनिघ्नैः संकीर्णैर्नानार्थैरव्ययैरपि ॥
लिङ्गादिसंग्रहैर्वर्गाः सामान्ये वर्गसंश्रयाः ॥ १ ॥
स्त्रीदाराद्यैर्यद्विशेष्यं यादृशैः प्रस्तुतं पदैः ॥
गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ २ ॥
सुकृती पुण्यवान् धन्यो महेच्छस्तु महाशयः ॥
हृदयालुः सुहृदयो महोत्साहो महोद्यमः ॥ ३ ॥
प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ॥
वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४ ॥
पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः ॥
दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि ॥ ५ ॥
स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे ॥
जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥ ६ ॥
परीक्षकः कारणिको वरदस्तु समर्धकः ॥
हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥ ७ ॥
दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः ॥
दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि ॥ ८ ॥
तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः ॥
प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ॥ ९ ॥

मतीते तु कृतलक्षणाहतलक्षणौ ॥
आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता ॥ १० ॥
भूर्नायको नेता प्रभुः परिवृढोऽधिपः ॥
र्द्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः ॥ ११ ॥
भ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् ॥
गरूपोपेतो यः सिंहसंहननो हि सः ॥ १२ ॥
ः कार्यकर्ता यः संपन्नः सत्वसंपदा ॥
च मूकोऽथ मनोजवसः पितृसंनिभः ॥ १३ ॥
यालंकृतां कन्यां यो ददाति स कूकुदः ॥
वाँल्लक्ष्मणः श्रीलः श्रीमान् स्निग्धस्तु वत्सलः ॥ १४ ॥
यालुः कारुणिकः कृपालुः सूरतः समाः ॥
तोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः ॥ १५ ॥
ः पराधीनः परवान्नाथवानपि ॥
निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ ॥ १६ ॥
स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः ॥
ऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः ॥ १७ ॥
तोऽलंकर्मीणः क्रियावान्कर्मसूद्यतः ॥
र्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः ॥ १८ ॥
भुक्कर्मकरः कर्मकारस्तु तत्क्रियः ॥
तो मृतस्नात आमिषाशी तु शौष्कुलः ॥ १९ ॥
तः स्यात्क्षुधितो जिघत्सुरशनायितः ॥
परपिण्डादो भक्षको घस्मरोऽद्मरः ॥ २० ॥

WORLD KONKANI CENTRE

आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते ॥
उभौ त्वात्मंभरिः कुक्षिंभरिः स्वोदरपूरके ॥ २१ ॥
सर्वान्नीनस्तु सर्वान्नभोजी गृध्नस्तु गर्धनः ॥
लुब्धोभिलाषुकस्तृष्णक् समौ लोलुपलोलुभौ ॥ २२ ॥
सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः ॥
मत्ते शौण्डोत्कटक्षीबाः कामुके कमिऽतानुकः ॥ २३ ॥
कम्रः कामयिताऽभीकः कमनः कामनोऽभिकः ॥
विधेयो विनयग्राही वचने स्थित आश्रवः ॥ २४ ॥
वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः ॥
धृष्टे धृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते ॥ २५ ॥
स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते ॥
अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः ॥ २६ ॥
आशंसुराशंसितरि गृहयालुर्ग्रहीतरि ॥
श्रद्धालुः श्रद्धया युक्ते पतयालुस्तु पातुके ॥ २७ ॥
लज्जाशीलेऽपत्रपिष्णुर्वन्दारुरभिवादके ॥
शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुस्तु वर्धनः ॥ २८ ॥
उत्पतिष्णुस्तूत्पतिताऽलंकरिष्णुस्तु मण्डनः ॥
भूष्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समौ ॥ २९ ॥
निराकारिष्णुः क्षिप्नुः स्यात्सान्द्रस्निग्धस्तु मेदुरः ॥
ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः ॥ ३० ॥
विसृत्वरो विसृमरः प्रसारी च विसारिणी ॥
सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी ॥ ३१ ॥

नोऽमर्षणः कोपी चण्डस्त्वत्यन्तकोपनः ॥
रूको जागरिता घूर्णितः प्रचलायितः ॥ ३२ ॥
ह् शयालुर्निद्रालुर्निद्राणशायितौ समौ ॥
मुखः पराचीनः स्यादवाङ्प्यधोमुखः ॥ ३३ ॥
ञ्चति देवद्र्यङ् विष्वद्र्यङ् विष्वगञ्चति ॥
हाञ्चति सध्र्यङ् स स तिर्यङ्यस्तिरोऽञ्चति ॥ ३४ ॥
वदावदो वक्ता वागीशो वाक्पतिः समौ ॥
युक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि ॥ ३५ ॥
जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक ॥
मुखराबद्धमुखौ शक्लः प्रियंवदे ॥ ३६ ॥
ः स्यादस्फुटवाग्गर्ह्यवादी तु कद्वदः ॥
कुवादकुचरौ स्यादसौम्यस्वरोऽस्वरः ॥ ३७ ॥
शब्दनो नान्दीवादी नान्दीकरः समौ ॥
ज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते ॥ ३८ ॥
शीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे ॥
ासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः ॥ ३९ ॥
गर्वोऽभिभूतः स्याद्दापितः साधितः समौ ॥
दिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः ॥ ४० ॥
ः स्याद्विप्रकृतो विप्रलब्धस्तु वञ्चितः ॥
तः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ ४१ ॥
क्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ ॥
न आपत्प्राप्तः स्यात्कांदिशीको भयद्रुतः ॥ ४२ ॥

आक्षारितः क्षारितोऽभिशस्ते संकसुकोऽस्थिरे ॥
व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ ॥ ४३ ॥
विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः ॥
कश्यः कशार्हे संनद्धे त्वाततायी वधोद्यते ॥ ४४ ॥
द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ ॥
विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः ॥ ४५
शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ ॥
दोषैकदृक् पुरोभागी निकृतस्त्वनृजुः शठः ॥ ४६ ॥
कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः ॥
नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः ॥ ४७ ॥
अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः ॥
कदर्ये कृपणक्षुद्रकिंपचानमितंपचाः ॥ ४८ ॥
निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः ॥
वनीयको याचनको मार्गणो याचकार्थिनौ ॥ ४९ ॥
अहंकारवानहंयुः शुभंयुस्तु शुभान्वितः ॥
दिव्योपपादुका देवा नृगवाद्या जरायुजाः ॥ ५० ॥
स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः ॥

॥ इति प्राणिवर्गः ॥

उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् ॥ ५१ ॥
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् ॥
कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ ५२
तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् ॥
अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम ॥ ५३ ।

प्रतिकृष्टार्वरेफयाप्यावमाधमाः ॥
कुत्सितावद्यखेटगर्ह्याणकाः समाः ॥ ५४ ॥
मसं तु मलिनं कच्चरं मलदूषितम् ॥
ावित्रं मेध्यं च वीध्रं तु विमलार्थकम् ॥ ५५ ॥
क्तं शोधितं मृष्टं निःशोध्यमनवस्करम् ॥
फल्गु शून्यं तु वशिकं तुच्छरिक्तके ॥ ५६ ॥
प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ॥
वर्यवरेण्याश्च प्रवर्होऽनवरार्ध्यवत् ॥ ५७ ॥
ाग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम् ॥
श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने ॥ ५८ ॥
रपदे व्याघ्रपुंगवर्षभकुञ्जराः ॥
ार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥ ५९ ॥
यं द्वयहीने द्वे अप्रधानोपसर्जने ॥
टं पृथु बृहद्विशालं पृथुलं महत् ॥ ६० ॥
विपुलं पीनपीन्वी तु स्थूलपीवरे ॥
ल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु ॥ ६१ ॥
मात्रा त्रुटिः पुंसि लवलेशकणाणवः ॥
ऽल्पिष्टमल्पीयः कनीयोऽणीय इत्यपि ॥ ६२ ॥
प्रचुरं प्राज्यमदभ्रं बहुलं बहु ॥
पुरु भूयिष्ठं स्फारं भूयश्च भूरि च ॥ ६३ ॥
ाद्यास्ते येषां परा संख्या शतादिकात् ॥
ये तु गणेयं संख्याते गणितमथ समं सर्वम् ॥ ६४ ॥

विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् ॥
समग्रं सकलं पूर्णमखण्डं स्यादनूनके ॥ ६५ ॥
घनं निरन्तरं सान्द्रं पेलवं विरलं तनु ॥
समीपे निकटासन्नसंनिकृष्टसनीडवत् ॥ ६६ ॥
सदेशाभ्याशसविधसमर्यादसवेशवत् ॥
उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ॥ ६७ ।
संसक्ते त्वव्यवहितमपदान्तरमित्यपि ॥
नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम् ॥ ६८ ॥
दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम् ॥
वर्तुलं निस्तलं वृत्तं बन्धुरंतून्नतानतम् ॥ ६९ ॥
उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने ॥
न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानतम् ॥ ७० ॥
अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् ॥
आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ॥ ७१ ॥
ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ ॥
शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः ॥ ७२ ॥
स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः ॥
कालव्यापि स कूटस्थः स्थावरो जङ्गमेतरः ॥ ७३ ।
चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् ॥
चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम् ॥ ७४ ।
चञ्चलं तरलं चैव पारिप्लवपरिप्लवे ॥
अतिरिक्तः समधिको दृढसंधिस्तु संहतः ॥ ७५ ॥

कठिनं क्रूरं कठोरं निष्ठुरं दृढम् ॥
मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम् ॥ ७६ ॥
प्रतनप्रत्नपुरातनचिरंतनाः ॥
ग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ॥ ७७ ॥
श्च सुकुमारं तु कोमलं मृदुलं मृदु ॥
गन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ॥ ७८ ॥
क्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम् ॥
ानोऽनन्यवृत्तिरेकाग्रैकायनावपि ॥ ७९ ॥
कसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः ॥
ादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् ॥ ८० ॥
जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः ॥
निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ॥ ८१ ॥
रणं तु सामन्यमेकाकी त्वेक एककः ॥
र्थका अन्यतर एकस्त्वोऽन्येतरावपि ॥ ८२ ॥
चं नैकभेदमुच्चण्डमविलम्बितम् ॥
दं तु मर्मस्पृगबाधं तु निरर्गलम् ॥ ८३ ॥
यं प्रतिकूलं स्यादपसव्यमपष्ठु च ॥
शरीरं सव्यं स्यादपसव्यं तु दक्षिणम् ॥ ८४ ॥
ना तु संबाधः कलिलं गहनं समे ॥
र्णे संकुलाकीर्णे मुण्डितं परिवापितम् ॥ ८५ ॥
तं संदितं दृब्धं विसृतं विस्तृतं ततम् ॥
गतं विस्मृतं स्यात्प्राप्तप्रणिहिते समे ॥ ८६ ॥

वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते ॥
नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः ॥ ८७ ॥
परिक्षिप्तं तु निवृतं मूषितं मूषितार्थकम् ॥
प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते ॥ ८८ ॥
निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते ॥
द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते ॥ ८९ ॥
घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे ॥
वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम् ॥ ९० ॥
रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते ॥
स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते ॥ ९१ ॥
वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः ॥
प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम् ॥ ९२
संगूढः स्यात्संकलितोऽवगीतः ख्यातगर्हणः ॥
विविधः स्याद्बहुविधो नानारूपः पृथग्विधः ॥ ९३ ॥
अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः ॥
अनायासकृतं फाण्टं स्वनितं ध्वनितं समे ॥ ९४ ॥
बद्धे संदानितं मूतमुद्दितं संदितं सितम् ॥
निष्पक्वे क्वथितं पाके क्षीराज्यहविषां शृतम् ॥ ९५ ॥
निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले ॥
पक्वं परिणते गूनं हन्ने मीढं तु मूत्रिते ॥ ९६ ॥
पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते ॥
दान्तस्तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः ॥ ९७

तु ज्ञापिते छन्नश्छादिते पूजितेऽञ्चितः ॥
तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः ॥ ९८ ॥
लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते ॥
तच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते ॥ ९९ ॥
प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ ॥
निर्वृत्तानिष्पन्नौ दारिते भिन्नभेदितौ ॥ १०० ॥
स्यूतमुतं चेति त्रितयं तन्तुसंतते ॥
दर्हिते नमस्यितनमसितमपचायितार्चितापचितम् ॥ १०१ ॥
वासिते वरिवस्यितमुपासितं चोपचरितं च ॥
पितसंतप्तौ धूपितधूपायितौ च दूनश्च ॥ १०२ ॥
मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः ॥
छातं लूनं कृत्तं दातं दितं छितं वृक्णम् ॥ १०३ ॥
ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् ॥
प्राप्तं विन्नं भावितमासादितं च भूतं च ॥ १०४ ॥
षितं गवेषितमन्विष्टं मार्गितं मृगितम् ॥
सार्द्रं क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तं च ॥ १०५ ॥
त्राणं रक्षितमवितं गोपायितं च गुप्तं च ॥
गणितमवमतावज्ञातेऽवमानितं च परिभूते ॥ १०६ ॥
हीनं विधुतं समुज्झितं धूतमुत्सृष्टे ॥
भाषितमुदितं जल्पितमाख्यातमाभिहितं लपितम् ॥ १०७ ॥
बुधितं मनितं विदितं प्रतिपन्नमवसितावगते ॥
कृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् ॥ १०८ ॥

संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् ॥
ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि ॥ १
अपि गीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि ॥
भक्षितचर्वितलीढप्रत्यवसितगिलितखादितप्सातम् ॥
अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते ॥
क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ॥ १११ ॥
क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुलप्रकर्षार्थाः ॥
साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः ॥ ११२ ॥
वाढव्यायतबहुगुरुवामनवृन्दारकातिशये ॥

॥ इति विशेष्यानिघ्नवर्गः ॥ १ ॥

प्रकृतिप्रत्ययार्थाद्यैः संकीर्णे लिङ्गमुन्नयेत् ॥
कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः ॥ १ ॥
साकल्यासंगवचने पारायणतुरायणे ॥
यदृच्छा स्वैरिता हेतुशून्या त्वास्या विलक्षणम् ॥ २
शमथस्तु शमः शान्तिर्दान्तिस्तु दमथो दमः ॥
अवदानं कर्म वृत्तं काम्यदानं प्रवारणम् ॥ ३ ॥
वशक्रिया संवननं मूलकर्म तु कार्मणम् ॥
विधूननं विधुवनं तर्पणं प्रीणनावनम् ॥ ४ ॥
पर्याप्तिः स्यात्परित्राणं हस्तवारणमित्यपि ॥
सेवनं सीवनं स्यूतिर्विदरः स्फुटनं भिदा ॥ ५ ॥
आक्रोशनमभीषङ्गः संवेदो वेदना न ना ॥
संमूर्छनमभिव्याप्तिर्याच्ञा भिक्षाऽर्थनाऽर्दना ॥ ६ ॥

छेदनेऽथ द्वे आनन्दनसभाजने ॥
च्छन्नमथाम्नायः संप्रदायः क्षये क्षिया ॥ ७ ॥
ग्राहो वशः कान्तौ रक्षणस्त्राणे रणः क्वणे ॥
वेधे पचा पाके हवो हूतौ वरो वृतौ ॥ ८ ॥
प्लोषे नयो नाये ज्यानिर्जीर्णौ भ्रमो भ्रमौ ॥
तेर्वृद्धौ प्रथा ख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे ॥ ९ ॥
समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा ॥
तेः प्रसवे श्च्योते प्राघारः क्लमथः क्लमे ॥ १० ॥
र्षोऽतिशये संधिः श्लेषे विषय आश्रये ॥
यां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे ॥ ११ ॥
य उन्नये श्रायः श्रयणे जयने जयः ॥
दो निगदे मादो मद उद्वेग उद्भ्रमे ॥ १२ ॥
नं परिमलोऽभ्युपपत्तिरनुग्रहः ॥
हस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः ॥ १३ ॥
न्धस्तु संग्राहो डिम्बे डमरविप्लवौ ॥
नं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि ॥ १४ ॥
रो विप्रकारः स्यादाकारस्त्वङ्ग इङ्गितम् ॥
णामो विकारो द्वे समे विकृतिविक्रिये ॥ १५ ॥
हारस्त्वपचयः समाहारः समुच्चयः ॥
हार उपादानं विहारस्तु परिक्रमः ॥ १६ ॥
हारोऽभिग्रहणं निर्हारोऽभ्यवकर्षणम् ॥
रोऽनुकारः स्यादर्थस्यापगमे व्ययः ॥ १७ ॥

प्रवाहस्तु प्रवृत्तिः स्यात्प्रवहो गमनं बहिः ॥
वियामो वियमो यामो यमः संयामसंयमौ ॥ १८ ॥
हिंसाकर्माभिचारः स्याज्जागर्या जागरा द्वयोः ॥
विघ्नोऽन्तरायः प्रत्यूहः स्यादुपघ्नोऽन्तिकाश्रये ॥ १
निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया ॥
विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः ॥ २० ॥
संक्षेपणं समसनं पर्यवस्था विरोधनम् ॥
परिसर्या परीसारः स्यादास्या त्वासना स्थितिः ॥
विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः ॥
संवाहनं मर्दनं स्याद्विनाशः स्याददर्शनम् ॥ २२ ॥
संस्तवः स्यात्परिचयः प्रसरस्तु विसर्पणम् ॥
नीवाकस्तु प्रयामः स्यात्संनिधिः संनिकर्षणम् ॥ २३
लवोऽभिलावो लवने निष्पावः पवने पवः ॥
प्रस्तावः स्यादवसरस्त्रसरः सूत्रवेष्टनम् ॥ २४ ॥
प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ ॥
धीशक्तिर्निष्क्रमोऽस्त्री तु संक्रमो दुर्गसंचरः ॥ २५
प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः ॥
स्यादभ्यादानमुद्घात आरम्भः संभ्रमस्त्वरा ॥ २६ ।
प्रतिबन्धःप्रतिष्टम्भोऽवनायस्तु निपातनम् ॥
उपलम्भस्त्वनुभवः समालम्भो विलेपनम् ॥ २७
विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम् ॥
विश्रावस्तु प्रतिख्यातिरवेक्षा प्रतिजागरः ॥ २८

ठनिपठौ पाठे तेमस्तेमौ समुन्दने ॥
नवास्रवौ क्लेशे मेलके सङ्गसंगमौ ॥ २९ ॥
क्षणं विचयनं मार्गणं मृगणा मृगः ॥
म्भः परिष्वङ्गः संश्लेष उपगूहनम् ॥ ३० ॥
नं तु निध्यानं दर्शनालोकनेक्षणम् ॥
ख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥ ३१ ॥
यो विशायश्च पर्यायशयनार्थकौ ॥
च ऋतीया च हृणीया च घृणार्थकाः ॥ ३२ ॥
त्यासो विपर्यासो व्यत्ययश्च विपर्यये ॥
ऽतिक्रमस्तस्मिन्नतिपात उपात्ययः ॥ ३३ ॥
यत्समाहूय तत्र स्यात्प्रतिशासनम् ॥
तावः क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम् ॥ ३४ ॥
तक्ष्यते यत्र काष्ठे काष्ठं स उद्घनः ॥
स्तु स्तम्बघनः स्तम्बो येन निहन्यते ॥ ३५ ॥
विध्यते येन तत्र विष्वक्समे निघः ॥
श्च निकारश्च द्वौ धान्योत्क्षेपणार्थकौ ॥ ३६ ॥
द्गारविक्षावोद्ग्राहास्तु गरणादिषु ॥ ३७ ॥
वरातिविरतय उपरामेऽथास्त्रियां तु निष्ठेवः ॥
तिर्निष्ठेवननिष्ठीवनामित्याभिन्नानि ॥ ३८ ॥
जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः ॥
पशुप्रेरणमकरणिरित्यादयः शापे ॥ ३९ ॥
यस्तस्य वृन्दमित्यौपगवकादिकम् ॥

आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् ॥ ४० ॥
माणवानां तु माणव्यं सहायानां सहायता ॥
हल्या हलानां ब्राह्मण्यवाडव्ये तु द्विजन्मनाम् ॥
द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमनुक्रमात् ॥
खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम् ॥ ४
ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक्
अपि साहस्रकारीषवार्मणाथर्वणादिकम् ॥ ४३ ॥

॥ इति संकीर्णवर्गः ॥ २ ॥

नानार्थाः केऽपि कान्तादिवर्गेष्वेवात्र कीर्तिताः ॥
भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते ॥ १
आकाशे त्रिदिवे नाको लोकस्तु भुवने जने ॥
पद्ये यशसि च श्लोकः शरे खड्गे च सायकः ॥ २
जम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ ॥
आलोकौ दर्शनद्योतौ भेरीपटहमानकौ ॥ ३ ॥
उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः ॥
तक्षको नागवर्धक्योरर्कः स्फाटिकसूर्ययोः ॥ ४ ॥
मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोम्बुनोः
स्यात्पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ॥ ५
उलूके करिणः पुच्छमूलोपान्ते च पेचकः ॥
कमण्डलौ च करकः सुगते च विनायकः ॥ ६
किष्कुहस्ते वितस्तौ च शूककीटे च वृश्चिकः ।
प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु पुंस्ययम् ॥ ७ ॥

तिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च ॥
त्नकायां च घोषे च कोशातक्यथ कट्फले ॥ ८ ॥
व खदिरे सोमवल्कः स्यादथ सिह्लके ॥
ल्के च पिण्याको बाह्लीकं रामठेऽपि च ॥ ९ ॥
ुग्गुलूलूकव्यालग्राहिषु कौशिकः ॥
शङ्कास्वातङ्कः स्वल्पेपि क्षुल्लकास्त्रिषु ॥ १० ॥
कः शशाङ्केऽपि खुरेऽप्यश्वस्य वर्तकः ॥
ऽपि पुण्डरीको ना यवान्यामपि दीपकः ॥ ११ ॥
ुकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम् ॥
ऽपि व्यलिकं स्यादलीकं त्वप्रियेऽनृते ॥ १२ ॥
न्वयावनूके द्वे शल्के शकलवल्कले ॥
ते सुवर्णानां हेम्न्युरोभूषणे पले ॥ १३ ॥
ऽपि च निष्कोऽस्त्री कल्कोऽस्त्री शमलैनसोः ॥
ऽथ पिनाकोऽस्त्री शूलशंकरधन्वनोः ॥ १४ ॥
तु करेण्वां च मेघजाले च कालिका ॥
ा यातनावृत्त्योः कर्णिका कर्णभूषणे ॥ १५ ॥
तेऽङ्गुलौ पद्मबीजकोश्यां त्रिषूत्तरे ॥
कौ रूपिमुख्यावेके मुख्यान्यकेवलाः ॥ १६ ॥
म्भकः कौक्कुटिको यश्चादूरेरितेक्षणः ॥
ेकः प्रभोर्भालदर्शी कार्याक्षमश्च यः ॥ १७ ॥
ितम्बवलयचक्रेषु कटकोऽस्त्रियाम् ॥
क्षुद्रशक्तौ च रोमहर्षे च कण्टकः ॥ १ ॥

पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः ॥
पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः ॥
पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः ॥
खेटकौ ग्रामफलकौ धीवरेऽपि च जालिकः ॥ ३ ॥
पुष्परेणौ च किंजल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च
स्यात्कल्लोलेऽप्युत्कलिका वार्द्धकं भाववृन्दयोः ॥ ४
करिण्यां चापि गणिका दारकौ बालभेदकौ ॥
अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ ॥ ५ ॥

॥ इति कान्ताः ॥

मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ ॥
शङ्खो निधौ ललाटास्थ्नि कम्बौ न स्त्रीन्द्रियेऽपि ख
घृणिज्वाले अपि शिखे—

॥ इति खान्ताः ॥

शैलवृक्षौ नगावगौ ॥
आशुगौ वायुविशिखौ शरार्कविहगाः खगाः ॥ १
पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः ॥
पशवोऽपि मृगा वेगः प्रवाहजवयोरपि ॥ २० ॥
परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि ॥
गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च ॥ २
सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु ॥
योगः संनहनोपायध्यानसंगतियुक्तिषु ॥ २२ ॥
भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः ॥

हरिणे पुंसि सारङ्गः शबले त्रिषु ॥ २३ ॥
प्लवगः शापे त्वभिषङ्गः पराभवे ॥
ङ्गे युगः पुंसि युगं युग्मे कृतादिषु ॥ २४ ॥
शुवाग्वज्रादिङ्नेत्रघृणिभूजले ॥
या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः ॥ २५ ॥
धान्यसान्वोश्च वराङ्गं मूर्धगुह्ययोः ॥
कामममाहात्म्यवीर्ययत्नार्ककीर्तिषु ॥ २६ ॥

॥ इति गान्ताः ॥

परिघातेऽस्त्रेऽप्योघो वृन्देऽम्भसां रये ॥
जाविधावर्घोऽहोदुःखव्यसनेष्वघम् ॥ २७ ॥
ऽल्पे लघुः–

॥ इति घान्ताः ॥

काचाः शिक्यमृद्भेदद्दग्रुजः ॥
विस्तरे च प्रपञ्चः पावके शुचिः ॥ २८ ॥
ये चात्युपधे पुंसि मेध्ये सिते त्रिषु ॥
ङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् ॥ २९ ॥

॥ इति चान्ताः ॥

भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः ॥
श्वले कच्छो जलप्रान्ते त्रिलिङ्गकः ॥ ६ ॥)

॥ इति क्षेपकच्छान्तः ॥

र्यावहिभुजौ दन्तविप्राण्डजा द्विजाः ॥
ष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः ॥ ३० ॥

धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् ।
वलजे क्षेत्रपूर्द्वारे वलजा वल्गुदर्शना ॥ ३१ ॥
समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्संततौ जने ॥
अब्जौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु ॥

॥ इति जान्ताः ॥

पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः ॥
संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना ॥ ३३

॥ इति ञान्ताः ॥

काकेभगण्डौ करटौ गजगण्डकटी कटौ ॥
शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे ॥ ३४ ॥
देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न द्वयोः ॥
रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ॥ ३५ ॥
रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे ॥
मायानिश्चलयन्त्रेषु कैतवानृतराशिषु ॥ ३६ ॥
अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् ॥
सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा
आत्युत्कर्षाश्रयः कोट्यो मूले लग्नकचे जटा ॥
व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेऽक्ष्णि दर्शने ॥
इष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु ॥
कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु च ॥ ३९
पटू द्वौ वाच्यलिंगौ च

॥ इति टान्ताः ॥

नीलकण्ठः शिवेऽपि च ॥
ाष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा ॥ ४० ॥
नेष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि ॥
ष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः ॥ ४१ ॥

॥ इति ठान्ताः ॥

ो लगुडेऽपि स्याद्गुडो गोलेक्षुपाकयोः ॥
ात्पशू व्याडौ गोभूवाचस्त्विडा इलाः ॥ ४२ ॥
वंशशलाकाऽपि नाडी नालेपि षट्क्षणे ॥
स्त्री दण्डबाणार्ववर्गावसरवारिषु ॥ ४३ ॥
डमश्वाभरणेऽमत्रे मूलवणिग्धने ॥

॥ इति डान्ताः ॥

ययोर्बाढं प्रगाढं भृशकृच्छ्रयोः ॥ ४४ ॥
ौ त्रिषु दृढौ व्यूढौ विन्यस्तसंहतौ ॥

॥ इति ढान्ताः ॥

ंके स्त्रैणगर्भे बाणो बलिसुते शरे ॥ ४५ ॥
सूक्ष्मे धान्यांशे संघाते प्रमथे गणः ॥
ूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥ ४६ ॥
द्रव्याश्रिते सत्त्वशौर्यसंध्यादिके गुणः ॥
ारास्थितौ कालविशेषोत्सवयोः क्षणः ॥ ४७ ॥
जादौ शुक्लादौ स्तुतौ वर्णं तु वाऽक्षरे ॥
भास्करेऽपि स्याद्वर्णभेदेपि च त्रिषु ॥ ४८ ॥

स्थाणुः शर्वोऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः
ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु ॥ ४९
ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः ॥
हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या ॥ ५० ॥
त्रिषु पाण्डौ च हरिणः स्थूणा स्तम्भेपि वेश्मनः ॥
तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे ॥ ५१ ॥
वणिक्पथे च विपणिः सुरा प्रत्यक् च वारुणी ॥
करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम् ॥ ५२ ॥
शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च ॥
विषाभिमरलोहेषु तीक्ष्णं क्लीबे खरे त्रिषु ॥ ५३ ॥
प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ॥
करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि ॥ ५४ ॥
प्राण्युत्पादे संसरणमसंबाधचमूगतौ ॥
घण्टापथेऽथ वान्तान्ने समुद्गिरणमुन्नये ॥ ५५ ॥
अतस्त्रिषु विषाणं स्यात्पशुशृङ्गेभदन्तयोः ॥
प्रवणं क्रमनिम्नोर्व्यां प्रह्वे ना तु चतुष्पथे ॥ ५६
संकीर्णौ निचिताशुद्धाविरिणं शून्यमूषरम् ॥
(सेतौ च वरणो वेणी नदीभेदे कचोच्चये ॥)

॥ इति णान्ताः ॥

देवसूर्यौ विवस्वन्तौ सरस्वन्तौ नदार्णवौ ॥ ५७
पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ ॥
अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ ॥ ५८

तु पाणिनक्षत्रे मरुतौ पवनामरौ ॥
हस्तिपके सूते भर्ता धातरि पोष्टरि ॥ ५९ ॥
त्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते ॥
ध्वजे केतुः पार्थिवे तनये सुतः ॥ ६० ॥
ः कारुभेदेऽपि भूभृद्भूमिधरे नृपे ॥
षिक्तो भूपेऽपि ऋतुः स्त्रीकुसुमेऽपि च ॥ ६१ ॥
वप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ ॥
प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने ॥ ६२ ॥
स्यात्सारथौ द्वाःस्थे क्षत्त्रियायां च शूद्रजे ॥
ःस्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः ॥ ६३ ॥
ः समरे नृत्यस्थाननीवृद्विशेषयोः ॥
ा यमसिद्धान्तदैवाकुशलकर्मसु ॥ ६४ ॥
दि रसरक्तादि महाभूतानि तद्गुणाः ॥
ण्यश्मविकृतिः शब्दयोनिश्च धातवः ॥ ६५ ॥
रेऽपि शुद्धान्तो नृपस्यासर्वगोचरे ॥
ामर्थ्ययोः शक्तिर्मूर्तिः काठिन्यकाययोः ॥ ६६ ॥
वल्ल्योर्व्रततिर्वसती रात्रिवेश्मनोः ॥
योरपचितिः सातिर्दानावसानयोः ॥ ६७ ॥
पीडाधनुष्कोट्योर्जातिः सामान्यजन्मनोः ॥
यन्दयोरीतिरीतिर्डिम्बप्रवासयोः ॥ ६८ ॥
धेगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे ॥
दुऽपि महती भूतिर्भस्मनि संपदि ॥ ६९ ॥

नदीनगर्योर्नागानां भोगवत्यथ संगरे ॥
सङ्गे सभायां समितिः क्षयवासावपि क्षिती ॥ ७० ॥
रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः ॥
जगती जगति छन्दोविशेषेऽपि क्षितावपि ॥ ७१ ॥
पङ्क्तिश्छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः ॥
पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः ॥ ७२ ॥
प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः ॥
सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः ॥ ७३ ॥
वनिता जनितात्यर्थानुरागायां च योषिति ॥
गुप्तिः क्षितिव्युदासेऽपि धृतिर्धारणधैर्ययोः ॥ ७४ ॥
बृहती क्षुद्रवार्ताकी छन्दोभेदे महत्यपि ॥
वासिता स्त्रीकरिण्योश्च वार्ता वृत्तौ जनश्रुतौ ॥ ७५ ॥
वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते ॥
कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः ॥ ७६ ॥
श्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम् ॥
अत्याहितं महाभीतिः कर्म जीवानपेक्षि च ॥ ७७ ॥
युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु ॥
वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले ॥ ७८ ॥
महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु ॥
श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु ॥ ७९ ॥
त्रिष्वतो जगदिङ्गेऽपि रक्तं नील्यादिरागि च ॥
अवदातः सिते पीते शुद्धे बुद्धार्जुनौ सितौ ॥ ८० ॥

तिसंस्कृते मर्षिण्यभिनीतोऽथ संस्कृतम् ॥
लक्षणोपेतेऽप्यनन्तोऽनवधावपि ॥ ८१ ॥
हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे ॥
क्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ ॥ ८२ ॥
म्लपरुषौ शुक्तौ शिती धवलमेचकौ ॥
साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ॥ ८३ ॥
कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते ॥
तावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् ॥ ८४ ॥
न्निद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी ॥
मत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ ॥ ८५ ॥

॥ इति तान्ताः ॥

ऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु ॥
नागमयोस्तीर्थमृषिजुष्टे जले गुरौ ॥ ८६ ॥
र्थस्त्रिषु शक्तिस्थे संबद्धार्थे हितेऽपि च ॥
मीस्थौ क्षीणरागवृद्धौ वीथी पदव्यपि ॥ ८७ ॥
स्थानीयत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः ॥
शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ ॥ ७)

॥ इति थान्ताः ॥

भिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ ॥ ८८ ॥
वादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ ॥
रा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः ॥ ८९ ॥

निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः ॥
आरावे रुदिते त्रातर्याक्रन्दो दारुणे रणे ॥ ९० ॥
स्यात्प्रसादोऽनुरागेऽपि सूदः स्याद्व्यञ्जनेऽपि च ॥
गोष्ठाध्यक्षेऽपि गोविन्दो हर्षेऽप्यामोदवन्मदः ॥ ९१ ॥
प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् ॥
स्त्री संविज्ज्ञानसंभाषाक्रियाकाराजिनामसु ॥ ९२ ॥
धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत् ॥
पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु ॥ ९३ ॥
गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम् ॥
त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ ॥ ९४ ॥
मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ ॥
प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ ॥ ९५ ॥

॥ इति दान्ताः ॥

व्यामो वटश्च न्यग्रोधावुत्सेधः काय उन्नतिः ॥
पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ ॥ ९६ ॥
परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥
बन्धकं व्यसनं चेतः पीडाधिष्ठानमाधयः ॥ ९७ ॥
स्युः समर्थननीवाकनियमाश्च समाधयः ॥
दोषोत्पादेऽनुबन्धः स्यात्प्रकृत्यादिविनश्वरे ॥ ९८ ॥
मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥
विधुर्विष्णौ चन्द्रमसि परिच्छेदे बिलेऽवधिः ॥ ९९ ॥
विधिर्विधाने दैवेऽपि प्रणिधिः प्रार्थने चरे ॥

बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च ॥ १०० ॥
देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम् ॥
विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु ॥ १०१ ॥
वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही ॥
संधा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा ॥ १०२ ॥
मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि ॥
अतस्त्रिषु समुन्नद्धौ पण्डितंमन्यगर्वितौ ॥ १०३ ॥
ब्रह्मबन्धुरधिक्षेपे निर्देशेऽथावलम्बितः ॥
अविदूरोऽप्यवष्टब्धः प्रसिद्धौ ख्यातभूषितौ ॥ १०४ ॥

॥ इति धान्ताः ॥

सूर्यवह्नी चित्रभानू भानू रश्मिदिवाकरौ ॥
भूतात्मानौ धातृदेहौ मूर्खनीचौ पृथग्जनौ ॥ १०५ ॥
ग्रावाणौ शैलपाषाणौ पत्त्रिणौ शरपक्षिणौ ॥
तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ ॥ १०६ ॥
प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ ॥
द्वौ सारथिहयारोहौ वाजिनोऽश्वेषु पक्षिणः ॥ १०७ ॥
कुलेऽप्याभिजनो जन्मभूम्यामप्यथ हायनाः ॥
वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः ॥ १०८ ॥
क्लेशेऽपि वृजिनो विश्वकर्मार्कसुराशिल्पिनोः ॥
आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च ॥ १०९ ॥
शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः ॥
घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे ॥ ११० ॥

अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः ॥
इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्त्रिये नृपे ॥ १११ ॥
वाणिन्यौ नर्तकीदूत्यौ स्रवन्त्यामपि वाहिनी ॥
ह्लादिन्यौ वज्रतडितौ वन्दायामपि कामिनी ॥ ११२ ॥
त्वग्देहयोरपि तनुः सूनाऽधोजिह्विकापि च ॥
क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ ११३ ॥
मन्देऽथ केतनं कृत्ये केतावुपनिमन्त्रणे ॥
वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ॥ ११४ ॥
उत्साहने च हिंसायां सूचने चापि गन्धनम् ॥
आतञ्चनं प्रतीवापजवनाप्यायनार्थकम् ॥ ११५ ॥
व्यञ्जनं लाञ्छनं श्मश्रुनिष्ठानावयवेष्वपि ॥
स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् ॥ ११६ ॥
स्यादुद्यानं निःसरणे वनभेदे प्रयोजने ॥
अवकाशे स्थितौ स्थानं क्रीडादावपि देवनम् ॥ ११७ ॥
उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमेऽपि च ॥
व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च ॥ ११८ ॥
मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने ॥
निर्वर्तनोपकरणानुव्रज्यासु च साधनम् ॥ ११९ ॥
निर्यातनं वैरशुद्धौ दाने न्यासार्पणेपि च ॥
व्यसनं विपदि भ्रंशे दोषे कामजकोपजे ॥ १२० ॥
पक्ष्माक्षिलोम्नि किंजल्के तन्त्वाद्यंशेऽप्यणीयसि ॥
तिथिभेदे क्षणे पर्व वर्त्म नेत्रच्छदेऽध्वनि ॥ १२१ ॥

अकार्यगुह्ये कौपीनं मैथुनं संगतौ रते ॥
प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः ॥ १२२ ॥
प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः ॥
क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः ॥ १२३ ॥
गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे ॥
संनिवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः ॥ १२४ ॥
आच्छादने संपिधानमपवारणमित्युभे ॥
आराधनं साधने स्यादवाप्तौ तोषणेऽपि च ॥ १२५ ॥
अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि ॥
रत्नं स्वजातिश्रेष्ठेऽपि वने सलिलकानने ॥ १२६ ॥
तलिनं विरले स्तोके वाच्यलिङ्गं तथोत्तरे ॥
समानाः सत्समैके स्युः पिशुनौ खलसूचकौ ॥ १२७ ॥
हीनन्यूनावूनगर्ह्यौ वेगिशूरौ तरस्विनौ ॥
अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गतावपि ॥ १२८ ॥

॥ इति नान्ताः ॥

कलापो भूषणे बर्हे तूणीरे संहतावपि ॥
परिच्छेदे परीवापः पर्युप्तौ सलिलस्थितौ ॥ १२९ ॥
गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी ॥
बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम् ॥ १३० ॥
तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम् ॥
प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥ १३१ ॥
भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी ॥

(कुतपो मृगरोमोत्थपटे चाह्नोऽष्टमेंऽशके ॥)

॥ इति पान्ताः ॥

रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यालिङ्गकः ॥ १३२ ॥

॥ इति फान्ताः ॥

अन्तराभवसत्वेऽश्वे गन्धर्वो दिव्यगायने ॥
कम्बुर्ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ ॥ १३३ ॥
पूर्वोऽन्यालिङ्गः प्रागाह पुंबहुत्वेऽपि पूर्वजान् ॥

॥ इति बान्ताः ॥

कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ ॥ १३४ ॥
स्तम्भौ स्थूणाजडीभावौ शंभू ब्रह्मत्रिलोचनौ ॥
कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च ॥ १३५ ॥
स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् ॥
स्यान्महारजने क्लीबं कुसुम्भं करके पुमान् ॥ १३६ ॥
क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् ॥
सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः ॥ १३७ ॥

॥ इति भान्ताः ॥

किरणप्रग्रहौ रश्मी कपिभेकौ प्लवंगमौ ॥
इच्छामनोभवौ कामौ शौर्योद्योगौ पराक्रमौ ॥ १३८ ॥
धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः ॥
उपायपूर्वआरम्भ उपधा चाप्युपक्रमः ॥ १३९ ॥
वणिक्पथः पुरं वेदो निगमो नागरो वणिक् ॥

नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु ॥ १४० ॥
शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः ॥
स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मस्तु कुटिलेऽलसे ॥ १४१ ॥
उष्णेऽपि घर्मश्चेष्टालंकारे भ्रान्तौ च विभ्रमः ॥
गुल्मा रुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः ॥ १४२ ॥
क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु ॥
त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा ॥ १४३ ॥
ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ॥
सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु ॥ १४४ ॥
वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ ॥
जीर्णं च परिभुक्तं च यातयाममिदं द्वयम् ॥ १४५ ॥

॥ इति मान्ताः ॥

तुरंगगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ ॥
श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ ॥ १४६ ॥
पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः ॥
तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे ॥ १४७ ॥
प्रत्ययोधीनशपथज्ञानविश्वासहेतुषु ॥
रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ॥ १४८ ॥
स्थूलोच्चयस्त्वसाकल्ये नागानां मध्यमे गते ॥
समयाः शपथाचारकालसिद्धान्तसंविदः ॥ १४९ ॥
व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः ॥
अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽप्यथापदि ॥ १५० ॥

युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च ॥
पश्चाद्वस्थायि बलं समवायश्च संनयौ ॥ १५१ ॥
संघाते संनिवेशे च संस्त्यायः प्रणयास्त्वमी ॥
विस्रम्भयाच्ञाप्रेमाणो विरोधेऽपि समुच्छ्रयः ॥ १५२ ॥
विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥
निर्यासेऽपि कषायोऽस्त्री सभायां च प्रतिश्रयः ॥ १५३ ॥
प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ क्रुधि ॥
रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः ॥ १५४ ॥
वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये ॥
धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्म शुभाशुभम् ॥ १५५ ॥
कशेरुहेम्नोर्गाङ्गेयं विशल्या दन्तिकाऽपि च ॥
वृषाकपायो श्रीगौर्योरभिख्या नामशोभयोः ॥ १५६ ॥
आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् ॥
उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः ॥ १५७ ॥
छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः ॥
कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने ॥ १५८ ॥
कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः ॥
जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च ॥ १५९ ॥
गर्ह्याहीनौ च वक्तव्यौ कल्यौ सज्जनिरामयौ ॥
आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि ॥ १६० ॥
रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि ॥
न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते ॥ १६१ ॥

॥ इति यान्ताः ॥

निवहावसरौ वारौ संस्तरौ प्रस्तराऽध्वरौ ॥
गुरू गीष्पतिपित्राद्यौ द्वापरौ युगसंशयौ ॥ १६२ ॥
प्रकारौ भेदसादृश्ये आकाराविङ्गिताकृती ॥
किंशारू सस्यशूकेषु मरू धन्वधराधरौ ॥ १६३ ॥
अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ ॥
ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः कराः ॥ १६४ ॥
प्रदरा भङ्गनारीरुग्बाणा अस्राः कचा अपि ॥
अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूबरौ ॥ १६५ ॥
स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः ॥
मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु ॥ १६६ ॥
कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु संगरः ॥
वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि ॥ १६७ ॥
मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः ॥
आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते ॥ १६८ ॥
अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च ॥
स्याज्जङ्गमे परीवारः खड्गकोषे परिच्छदे ॥ १६९ ॥
विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् ॥
द्वारि द्वाःस्थे प्रतीहारः प्रतिहार्यप्यनन्तरे ॥ १७० ॥
विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु ॥
सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु ॥ १७१ ॥
दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम् ॥
महारण्ये दुर्गपथे कान्तारं पुंनपुंसकम् ॥ १७२ ॥

मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु ॥
देवाद्वृते वरः श्रेष्ठ त्रिषु क्लीबं मनाक्प्रिये ॥ १७३ ॥
वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना ॥
ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् ॥ १७४ ॥
यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ॥
शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ १७५ ॥
शर्करा कर्परांशेऽपि यात्रा स्याद्यापने गतौ ॥
इरा भूवाक्सुराप्सु स्यात्तन्द्री निद्राप्रमीलयोः ॥ १७६ ॥
धात्री स्यादुपमाताऽपि क्षितिरप्यामलक्यपि ॥
क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ॥ १७७ ॥
त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे ॥
अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे ॥ १७८ ॥
आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः ॥
योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः ॥ १७९ ॥
निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः ॥
स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः ॥ १८० ॥
मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च ॥
सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च ॥ १८१ ॥
अजिरं विषये कायेऽप्यम्बरं व्योम्नि वाससि ॥
चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च ॥ १८२ ॥
स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम् ॥
गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे ॥ १८३ ॥

रोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् ॥
न्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे ॥ १८४ ॥
रोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ ॥
न्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे ॥ १८५ ॥
शीरश्चामरे दण्डेऽप्यौशीरं शयनासने ॥
ष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले ॥ १८६ ॥
योस्त्रि खड्गफले पद्मे तीर्थौषधिविशेषयोः ॥
न्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये ॥ १८७ ॥
छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ॥
स्तेऽपि पिठरं राजकेशरुण्यपि नागरम् ॥ १८८ ॥
र्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् ॥
रोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः ॥ १८९ ॥
ठरः कठिनेऽपि स्यादधस्तादपि चाधरः ॥
नाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले ॥ १९० ॥
पर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः ॥
षां विपर्यये श्रेष्ठं दूरानात्मोत्तमाः पराः ॥ १९१ ॥
वादुप्रियौ तु मधुरौ क्रूरौ कठिनानिर्दयौ ॥
दारो दातृमहतोरितरस्त्वन्यनीचयोः ॥ १९२ ॥
न्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः ॥

॥ इति रान्ताः ॥

डा किरीटं केशाश्च संयता मौलयस्त्रयः ॥ १९३ ॥
मभेदमातङ्गकाण्डपुष्पाणि पीलवः ॥

कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः ॥ १९४ ॥
स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः ॥
करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् ॥ १९५ ॥
स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः ॥
वातूलः पुंसि वात्यायामपि वातासहे त्रिषु ॥ १९६ ॥
भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः ॥
मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम् ॥ १९७ ॥
शङ्कावपि द्वयोः कीलः पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु ॥
कला शिल्पे कालभेदेऽप्याली सख्यावली अपि ॥ १९८
अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि ॥
बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु ॥ १९९ ॥
लीला विलासक्रिययोरुपला शर्करापि च ॥
शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः ॥ २०० ॥
जालं समूह आनायगवाक्षक्षारकेष्वपि ॥
शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम् ॥ २०१ ॥
छर्दिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना ॥
अधःस्वरूपयोरस्त्री तलं स्याच्चामिषे पलम् ॥ २०२ ॥
और्वानलेऽपि पातालं चैलं वस्त्रेऽधमे त्रिषु ॥
कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले ॥ २०३ ॥
निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः ॥
पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु ॥ २०४ ॥

प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च ॥
करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः ॥ २०५ ॥
मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः ॥

॥ इति लान्ताः ॥

दवदावौ वनारण्यवह्नी जन्महरौ भवौ ॥ २०६ ॥
मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः ॥
अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः ॥ २०७ ॥
भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ॥
स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने ॥ २०८ ॥
अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः ॥
उत्सेकामर्षयोरिच्छाप्रसवे मह उत्सवः ॥ २०९ ॥
अनुभावः प्रभावे च सतां च मतिनिश्चये ॥
स्याज्जन्महेतुः प्रभवः स्थानं चाद्योपलब्धये ॥ २१० ॥
शूद्रायां विप्रतनये शस्त्रे पारशवो मतः ॥
ध्रुवो भभेदे क्लीबं तु निश्चिते शाश्वते त्रिषु ॥ २११ ॥
स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने ॥
स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च ॥ २१२ ॥
शिवा गौरीफेरवयोर्द्वन्द्वं कलहयुग्मयोः ॥
द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु ॥ २१३ ॥
क्लीबं नपुंसकं षण्ढे वाच्यलिङ्गमविक्रमे ॥

॥ इति वान्ताः ॥

द्वौ विशौ वैश्यमनुजौ द्वौ चराभिमरौ स्पशौ ॥ २१४ ॥

द्वौ राशी पुञ्जमेषाद्यौ द्वौ वंशौ कुलमस्करौ ॥
रहःप्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः ॥ २१५ ॥
कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु ॥
पदे लक्ष्ये निमित्तेऽपदेशः स्यात्कुशमप्सु च ॥ २१६ ॥
दशाऽवस्थानेकविधाप्याशा तृष्णापि चायता ॥
वशा स्त्री करिणी च स्याद् दृग्ज्ञाने ज्ञातरि त्रिषु ॥ २१७
स्यात्कर्कशः साहसिकः कठोरामसृणावपि ॥
प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः ॥ २१८ ॥
(कोशोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः ॥ ८ ॥)

॥ इति शान्ताः ॥

सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ ॥
काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ तु तृणवीरुधौ ॥ २१९
अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने ॥
पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः ॥ २२० ॥
शुक्रले मूषके श्रेष्ठे सुकृते वृषभे वृषः ॥
कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघद्विव्ययोः ॥ २२१ ।
द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये ॥
ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे ॥ २२२ ॥
कर्षुर्वार्ता करीषाग्निः कर्षूः कुल्याभिदायिनी ॥
पुंभावे तत्क्रियायां च पौरुषं विषमप्सु च ॥ २२३ ॥
उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम् ॥
स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् ॥ २२४ ॥
प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः ॥

त्विद् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः ॥ २२५ ॥
प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे ॥

॥ इति षान्ताः ॥

रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू ॥ २२६ ॥
वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः ॥
शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः ॥ २२७ ॥
पुंस्युत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे ॥
देवभेदेऽनले रश्मौ वसू रत्ने धने वसु ॥ २२८ ॥
विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः ॥
लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च ॥ २२९ ॥
प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते ॥
ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु ॥ २३० ॥
पापापराधयोरागः खगबाल्यादिनोर्वयः ॥
तेजःपुरीषयोर्वर्चो महस्तूत्सवतेजसोः ॥ २३१ ॥
रजो गुणे च स्त्रीपुष्पे राहौ ध्वान्ते गुणे तमः ॥
छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च ॥ २३२ ॥
सहो बलं सहा मार्गो नभः खं श्रावणो नभाः ॥
ओकः सद्माश्रयश्चौकः पयः क्षीरं पयोऽम्बु च ॥ २३३ ॥
ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये ॥
तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु ॥ २३४ ॥
विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशये त्वमी ॥
वृद्धप्रशस्ययोर्ज्यायान्कनीयांस्तु युवाल्पयोः ॥ २३५ ॥

वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः ॥

॥ इति सान्ताः ॥

दलेऽपि बर्हं निर्बन्धोपरागार्कादयो ग्रहाः ॥ २३६ ॥
द्वार्यापीडे क्काथरसे निर्व्यूहो नागदन्तके ॥
तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च ॥ २३७ ॥
पत्नीपरिजनादानमूलशापाः परिग्रहाः ॥
दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः ॥ २३८ ॥
व्यूहो वृन्देऽप्याहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोऽपहाः ॥
परिच्छेदे नृपार्हेऽर्थे परिबर्हो—

॥ इति हान्ताः ॥

ऽव्ययाः परेः ॥ २३९ ॥
आङीषदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे ॥
आ प्रगृह्यः स्मृतौ वाक्येऽप्यास्तु स्यात्कोपपीडयोः ॥ २४०
पापकुत्सेषदर्थे कु धिङ् निर्भर्त्सननिन्दयोः ॥
चान्वाचयसमाहारेतरेतरसमुच्चये ॥ २४१ ॥
स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घनेऽप्यति ॥
स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे ॥ २४२ ॥
सकृत्सहैकवारे चाप्याराद्दूरसमीपयोः ॥
प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः ॥ २४३ ॥
पुनः सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः ॥
खेदानुकम्पासंतोषविस्मयामन्त्रणे बत ॥ २४४ ॥
हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥

प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः ॥ २४५ ॥
इति हेतुप्रकरणप्रकाशादिसमाप्तिषु ॥
प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि ॥ २४६ ॥
यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ॥
मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ ॥ २४७ ॥
वृथानिरर्थकाविध्योर्नानाऽनेकोभयार्थयोः ॥
नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु ॥ २४८ ॥
प्रश्नावधारणाऽनुज्ञानुनयामन्त्रणे ननु ॥
गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि ॥ २४९ ॥
उपमायां विकल्पे वा सामि त्वर्धे जुगुप्सिते ॥
अमा सह समीपे च कं वारिणि च मूर्धनि ॥ २५० ॥
इवेत्थमर्थयोरेवं नूनं तर्केऽर्थनिश्चये ॥
तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने ॥ २५१ ॥
नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने ॥
अलं भूषणपर्याप्तिशक्तिवारणवाचकम् ॥ २५२ ॥
हुं वितर्के परिप्रश्ने समयान्तिकमध्ययोः ॥
पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः ॥ २५३ ॥
स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ॥
ऊरर्यूरी चोररी च विस्तारेऽङ्गीकृतौ त्रयम् ॥ २५४ ॥
स्वर्गे परे च लोके स्ववार्तासंभाव्ययोः किल ॥
निषेधवाक्यालंकारजिज्ञासानुनये खलु ॥ २५५ ॥
समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः ॥
नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि ॥ २५६ ॥

तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगार्तिषु ॥
अहहेत्यद्भुते खेदे हि हेतावववधारणे ॥ २५७ ॥

॥ इति नानार्थवर्गः ॥ ३ ॥

चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः ॥
मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः ॥ १ ॥
स्राक् झटित्यञ्जसाह्नाय द्राङ् मङ्क्षु सपदि द्रुते ॥
बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे ॥ २ ॥
पृथग्विनान्तरेणर्ते हिरुङ् नाना च वर्जने ॥
यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन ॥ ३ ॥
कदाचिज्जातु सार्धं तु साकं सत्रा समं सह ॥
आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा ॥ ४ ॥
आहो उताहो किमुत विकल्पे किं किमूत च ॥
तु हि च स्म ह वै पादपूरणे पूजने स्वति ॥ ५ ॥
दिवाह्नीत्यथ दोषा च नक्तं च रजनाविति ॥
तिर्यगर्थे साचि तिरोऽप्यथ संबोधनार्थकाः ॥ ६ ॥
स्युः प्याट् पाडङ्ग हे है भोः समया निकषा हिरुक् ॥
अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः ॥ ७ ॥
स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधा ॥
किंचिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे ॥ ८ ॥
व वा यथा तथेवैवं साम्येऽहो ही च विस्मये ॥
मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे ॥ ९ ॥
दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा ॥

अन्तरण च मध्ये स्युः प्रसह्य तु हठार्थकम् ॥ १० ॥
युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते ॥
अभावे नह्य नो नापि मास्म मालं च वारणे ॥ ११ ॥
पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम् ॥
प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ॥ १२ ॥
समन्ततस्तु परितः सर्वतो विष्वगित्यपि ॥
अकामानुमतौ काममसूयोपगमेऽस्तु च ॥ १३ ॥
ननु च स्याद्विरोधोक्तौ कच्चित्कामप्रवेदने ॥
निःषमं दुःषमं गर्ह्ये यथास्वं तु यथातथम् ॥ १४ ॥
मृषा मिथ्या च वितथे यथार्थं तु यथातथम् ॥
स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः ॥ १५ ॥
प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम् ॥
संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना ॥ १६ ॥
अल्पे नीचैर्महत्युच्चैः प्रायोभूम्न्यद्रुते शनैः ॥
सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने ॥ १७ ॥
अस्ति सत्त्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि ॥
हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ ॥ १८ ॥
पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने ॥
सायं साये प्रगे प्रातः प्रभाते निकषाऽन्तिके ॥ १९ ॥
परुत्परार्यैषमोऽब्दे पूर्वे पूर्वतरे यति ॥
अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात् ॥ २० ॥
तथाऽधरान्यान्यतरेतरात्पूर्वेद्युरादयः ॥

उभयद्युश्चोभयेद्युः परे त्वह्नि परेद्यवि ॥ २१ ॥
ह्यो गते नागतेऽह्नि श्वः परश्वस्तु परेऽहनि ॥
तदा तदानीं युगपदेकदा सर्वदा सदा ॥ २२ ॥
एतर्हि संप्रतीदानीमधुना साम्प्रतं तथा ॥
दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः ॥ २३ ॥

॥ इत्यव्ययवर्गः ॥ ४ ॥

सलिङ्गशास्त्रैः सन्नादिकृत्तद्धितसमासजैः ॥
अनुक्तैः संग्रहे लिङ्गं संकीर्णवदिहोन्नयेत् ॥ १ ॥
लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाधितः ॥
स्त्रियामीदूद्विरामैकाच् सयोनिप्राणिनाम च ॥ २ ॥
नाम विद्युन्निशावल्लीवीणादिग्भूनदीह्रियाम् ॥
अदन्तैर्द्विगुरेकार्थो न स पात्रयुगादिभिः ॥ ३ ॥
तल् वृन्दे येनिकट्यत्रा वैरमैथुनिकादिवुन् ॥
स्त्रीभावादावनिक्तिण्ण्वुल्ण्च्ण्वुच्क्यब्युजिञङ्निशाः ॥ ४ ॥
उणादिषु निरूरीश्च ङ्याबूङन्तं चलं स्थिरम् ॥
तत्क्रीडायां प्रहरणं चेन्मौष्टा पाल्लवा ण दिक् ॥ ५ ॥
घञो ञः सा क्रियाऽस्यां चेद्दाण्डपाता ही फाल्गुनी ॥
श्यैनंपाता च मृगया तैलंपाता स्वधेति दिक् ॥ ६ ॥
स्त्री स्यात्काचिन्मृणाल्यादिर्विवक्षापचये यदि ॥
लङ्का शेफालिका टीका धातकी पञ्जिकाऽऽढकी ॥ ७ ॥
सिध्रका सारिका हिक्का प्राचिकोल्का पिपीलिका ॥
तिन्दुकी कणिका भङ्गिः सुरङ्गासूचिमाढयः ॥ ८ ॥

पिच्छावितण्डाकाकिण्यश्चूर्णिः शाणी द्रुणी दरत् ॥
सातिः कन्था तथाऽऽसन्दीनाभी राजसभापि च ॥ ९ ॥
झल्लरी चर्चरी पारी होरा लट्वा च सिध्मला ॥
लाक्षा लिक्षा च गण्डूषा गृध्रसो चमसी मसी ॥ १० ॥

॥ इति स्त्रीलिङ्गसंग्रहः ॥

पुंस्त्वे सभेदानुचराः सपर्यायाः सुरासुराः ॥
स्वर्गयागाद्रिमेघाब्धिद्रुकालासिशरारयः ॥ ११ ॥
करगण्डोष्ठदोर्दन्तकण्ठकेशनखस्तनाः ॥
अह्नाहान्ताः क्ष्वेडभेदा रात्रान्ताः प्रागसंख्यकाः ॥ १२ ॥
श्रीवेष्टाद्याश्च निर्यासा असन्नन्ता अबाधिताः ॥
कशेरुजस्तुवस्तूनि हित्वा तुरुविरामकाः ॥ १३ ॥
कषणभमरोपान्ता यद्यदन्ता अमी अथ ॥
पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः ॥ १४ ॥
नाम्न्यकर्तरि भावे च घञजब्नङ्णवाथुचः ॥
ल्युः कर्तरीमनिज् भावे को घोः किः प्रादितोऽन्यतः ॥ १५ ॥
द्वन्द्वेऽश्ववडवावश्ववडवा न समाहृते ॥
कान्तः सूर्येन्दुपर्यायपूर्वोऽयः पूर्वकोऽपि च ॥ १६ ॥
वटकश्चानुवाकश्च रल्लकश्च कुडङ्गकः ॥
पुङ्खो न्यूङ्खः समुद्गश्च विटपट्टघटाः खटाः ॥ १७ ॥
कोट्टारघट्टहट्टाश्च पिण्डगोण्डपिचण्डवत् ॥
गडुः करण्डो लगुडो वरण्डश्च किणो घुणः ॥ १८ ॥
हलिसीमन्तहरितो रोमन्थोद्गीथ बुद्बुदाः ॥

कासमर्दोऽर्बुदः कुन्दः फेनस्तूपौ सयूपकौ ॥ १९ ॥
आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः ॥
पूरक्षुरप्रचुक्राश्च गोलहिङ्गुलपुद्गलाः ॥ २० ॥
वेतालभल्लमल्लाश्च पुरोडाशोऽपि पट्टिशः ॥
कुल्माषो रभसश्चैव सकटाहः पतद्ग्रहः ॥ २१ ॥

इति पुंलिङ्गशेषः ॥

द्विहीनेऽन्यच्च खारण्यपर्णश्वभ्रहिमोदकम् ॥
शीतोष्णमांसरुधिरमुखाक्षिद्रविणं बलम् ॥ २२ ॥
फलहेमशुल्बलोहसुखदुःखशुभाशुभम् ॥
जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम् ॥ २३ ॥
कोट्याः शतादिसंख्याऽन्या वा लक्षा नियुतं च तत् ॥
द्व्यच्कमसिसुसन्नन्तं यदनान्तमकर्तरि ॥ २४ ॥
त्रान्तं सलोपधं शिष्टं रात्रं प्राक्संख्ययान्वितम् ॥
पात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः ॥ २५ ॥
द्वन्द्वैकत्वाव्ययीभावौ पथः संख्याव्ययात्परः ॥
षष्ठ्याश्छाया बहूनां चेद्विच्छायं संहतौ सभा ॥ २६ ॥
शालार्थापि परा राजामनुष्यार्थादराजकात् ॥
दासीसभं नृपसभं रक्षःसभमिमा दिशः ॥ २७ ॥
उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने ॥
कोपज्ञकोपक्रमादिकन्थोशीनरनामसु ॥ २८ ॥
भावे नणकचिद्भ्योऽन्ये समूहे भावकर्मणोः ॥
अदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः ॥ २९ ॥

क्रियाव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके ॥
ोचं पिच्छं गृहस्थूणं तिरीटं मर्म योजनम् ॥ ३० ॥
ाजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः ॥
ाणिक्यभाष्यासिन्दूरचीरचीवरपिञ्जरम् ॥ ३१ ॥
ोकायतं हरितालं विदलस्थालबाह्लिकम् ॥

॥ इति क्लीबसंग्रहः ॥

ुंनपुंसकयोः शेषोऽर्धर्चपिण्याककण्टकाः ॥ ३२ ॥
ादकस्तण्डकष्टङ्कः शाटकः कर्पटोऽर्बुदः ॥
ातकोद्योगचरकतमालामलका नडः ॥ ३३ ॥
कुष्ठं मुण्डं शीधु बुस्तं क्ष्वेडितं क्षेमकुट्टिमम् ॥
ंगमं शतमानार्मशम्बलाव्ययताण्डवम् ॥ ३४ ॥
वियं कन्दकार्पासं पारावारं युगंधरम् ॥
यूपं प्रग्रीवपात्रीवे यूषं चमसचिक्कसौ ॥ ३५ ॥
अर्धर्चादौ घृतादीनां पुंस्त्वाद्यं वैदिकं ध्रुवम् ॥
न्नोक्तमिह लोकेऽपि तच्चेदस्त्यस्तु शेषवत् ॥ ३६ ॥

॥ इति पुंनपुंसकसंग्रहवर्गः ॥

त्रीपुंसयोरपत्यान्ता द्विचतुःषट्पदोरगाः ॥
ातिभेदाः पुमाख्याश्च स्त्रीयोगैः सह मल्लकः ॥ ३७ ॥
र्मिर्वराटकः स्वातिर्वर्णको झाटलिर्मनुः ॥
मूषा सृपाटी कर्कन्धूर्यष्टिः शाटी कटी कुटी ॥ ३८ ॥

॥ इति स्त्रीपुंसशेषसंग्रहवर्गः ॥

त्रीनपुंसकयोर्भावक्रिययोः ष्यञ् क्वचिच्च वुञ् ॥
ौचित्यमौचिती मैत्री मैत्र्यं वुञ् प्रागुदाहृतः ॥ ३९ ॥

षष्ठ्यन्तप्राक्पदाः सेनाछायाशालासुरानिशाः ॥
स्याद्वा नृसेनं श्वनिशं गोशालमितरे च दिक् ॥ ४० ॥
आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप् ॥
त्रिखट्वं च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि ॥ ४१

॥ इति स्त्रीनपुंसकशेषः ॥

त्रिषु पात्री पुटी वाटी पेटी कुवलदाडिमौ ॥

॥ इति त्रिलिङ्गशेषसंग्रहः ॥

परं लिङ्गं स्वप्रधाने द्वन्द्वे तत्पुरुषेऽपि तत् ॥ ४२ ॥
अर्थान्ताः प्राद्यलंप्राप्तापन्नपूर्वाः परोपगाः ॥
तद्धितार्थो द्विगुः संख्यासर्वनामतदन्तकाः ॥ ४३ ॥
बहुव्रीहिरदिङ्नाम्नामुन्नेयं तदुदाहृतम् ॥
गुणद्रव्यक्रियायोगोपाधिभिः परगामिनः ॥ ४४ ॥
कृतः कर्तर्यसंज्ञायां कृत्याः कर्तरि कर्मणि ॥
अणाद्यन्तास्तेन रक्ताद्यर्थे नानार्थभेदकाः ॥ ४५ ॥
षट्संज्ञकास्त्रिषु समा युष्मदस्मत्तिङव्ययम् ॥
परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगतः ॥ ४६ ॥

॥ इति लिङ्गादिसंग्रहवर्गः ॥ ५ ॥

इत्यमरसिंहकृतौ नामलिङ्गानुशासने ॥
सामान्यकाण्डस्तृतीयः साङ्ग एव समर्थितः ॥ ४७ ॥

तृतीयं काण्डं संपूर्णम् ॥

॥ समाप्तोऽयं ग्रन्थः ॥

श्रीः ।

अथामरकोशशब्दानुक्रमणिका ।

शब्दः	पृष्ठम्	श्लोकः
	अ	
अ	१३९	११
अंश	९१	८९
अंशु	१२	३३
अंशुक	६४	११५
अंशुमती	४४	११५
अंशुमत्फला	४४	११३
अंस	६०	७८
अंसल	५७	४४
अंहति	६९	३०
अंहस्	१४	२३
अकरणि	११९	३९
अकूपार	२४	१
अकृष्णकर्मन्	१०२	४६
अक्ष	३९ ८७ ९१ ९७ १३४	५८ ४३ ८६ ४५ २२२
अक्षत	८७	४७
अक्षदर्शक	७२	५
अक्षदेविन्	९७	४४

शब्दः	पृष्ठम्	श्लोकः
अक्षधूर्त	९७	४४
अक्षर	१३०	१८२
अक्षरचंचु	७३	१५
अक्षरचण	७३	१५
अक्षरविन्यास	७३	१६
अक्षवती	९७	४५
अक्षाग्रकीलक	७७	५६
अक्षान्ति	२१	२४
अक्षि	६२ १४२	९३ २२
अक्षिकूटक	७५	३८
अक्षिगत	१०२	४५
अक्षीव	३६ ८६	३१ ४१
अक्षोट	३६	२९
अक्षौहिणी	७९	८१
अखंड	१०४	६५
अखात	२७	२७
अखिल	१०४	६५
अग	११४	१९
अगद	५८	५०

शब्दः	पृष्ठम्
अगदंकार	५८
अगम	३४
अगस्त्य	१०
अगाध	२६
अगार	३१
अगुरु	६५
अगुरुशिंशपा	३९
अग्नायी	६८
अग्नि	६
अग्निकण	७
अग्निचित्	६७
अग्निज्वाला	४५
अग्नित्रय	६८
अग्निभू	५
अग्निमन्थ	३९
अग्निमुखी	३७
अग्निशिख	६४
अग्निशिखा	४४ ४६
अग्न्युत्पात	१३ ११८

शब्दानुक्रमणिका.

शब्दः	पृष्ठम्	श्लोकः
	१०३	५८
	१३१	१८४
	५७	४३
नू	६६	४
	७८	७२
	१३७	२४६
	१३८	७
	५९	६४
	५७	४३
	१०३	५८
	१०३	५८
तु	५२	२३
	७८	७२
	१०३	५८
	१४	२३
	११५	२७
	७१	४८
	८९	६७
	१०	१७
	११२	४
	३४	४
	७५	४१
	३६	२९
	२०	५
	६०	७०
	१३८	७
	१३९	१९

शब्दः	पृष्ठम्	श्लोकः
अङ्गद	६३	१०७
अङ्गन	३२	१३
अङ्गना	९	५
	५३	३
अङ्गविक्षेप	२१	१६
अङ्गसंस्कार	६४	१२१
अङ्गहार	२१	१६
अङ्गार	८५	३०
अङ्गारक	११	२५
अङ्गारधानिका	८५	२९
अङ्गारवल्लरी	३८	४८
अङ्गारवल्ली	४२	९०
अङ्गारशकटी	८५	२९
अङ्गीकार	१५	५
अङ्गीकृत	१०७	१०८
अंगुलिमान	९१	८५
अंगुलीमुद्रा	६३	१०८
अगुली	६९	८२
अंगुलीयक	६३	१०७
अंगुष्ठ	६९	८२
अङ्घ्रि	६०	७१
अङ्घ्रिनामक	३५	१२
अङ्घ्रिपर्णिका	४२	९२
अचंडी	८९	७०
अचल	३३	१
अचला	२९	२

शब्दः	पृष्ठम्	श्लोकः
अचिक्कण	१३५	
अच्छ	२६	
अच्छभल्ल	४९	
अच्युत	३	
अच्युताग्रज	३	
अज	९०	
	११५	
अजगंधिका	४६	
अजगर	२३	
अजगव	४	
अजन्य	८२	
अजमोदा	४७	१४
अजशृंगी	४४	११
अजस्र	७	
अजहा	४१	८
अजा	९०	
अजाजी	८६	३
अजाजीव	९४	
अजित	११९	
अजिन	७१	४
अजिनपत्रा	५१	२
अजिनयोनि	५०	
अजिर	३२	१
	१३०	१८
अजिह्म	१०४	
अजिह्मग	८०	८
अज्जका	२९	५

शब्दानुक्रमणिका.

शब्दः	पृष्ठम्	श्लोकः
अज्झटा	४५	१२८
अज्ञ	१०१	३८
	१०२	४८
अज्ञान	१६	७
अञ्चित	१०७	९८
अञ्जन	९	२
अञ्जनकेशी	४५	१३०
अञ्जनावती	९	५
अञ्जलि	६१	८५
अञ्जसा	१३८	२
	१३९	१२
अटनी	७९	८४
अटरूष	४३	१०३
अटवी	३४	१
अटा	६९	२६
अट्ट	३२	१२
	१२५	१२१
अट्या	६९	२६
अणक	१०३	५४
अणि	७७	५६
अणिमन्	४	३९
अणीयस्	१०३	६२
अणु	८५	२०
	१०३	६२
अण्ड	५३	३७
अण्डकोश	६०	७६

शब्दः	पृष्ठम्	श्लोकः
अण्डज	२६	१७
	५२	३३
	१०२	५१
अतट	३३	४
अतर्कित	१३८	७
अतलस्पर्श	२६	१५
अतसी	८५	२०
अति	१३६	२४२
	१३८	२
	१३८	५
अतिक्रम	१११	३३
	१२७	१५०
अतिचरा	४७	१४६
अतिछत्र	४९	१६७
अतिछत्रा	४७	१५२
अतिजव	७८	७३
अतिथि	६९	३४
अतिनिर्हारिन्	१६	१०
अतिनु	२६	१४
अतिपथिन्	३०	१६
अतिपात	७०	३७
	१११	३३
अतिप्रसिद्ध	१३४	२१८
अतिमात्र	८	७१
अतिमुक्त	४०	७२
अतिमुक्तक	३६	२६
अतिरिक्त	१०४	७५

शब्दः	पृष्ठम्
अतिवक्तृ	१०१
अतिवाङ्	१८
अतिविषा	४२
अतिवेल	८
अतिशक्तिता	८१
अतिशय	७
	१०९
अतिशस्त	११७
अतिशोभन	१०३
अतिसंस्कृत	१२१
अतिसर्जन	११०
अतिसारकिन्	५९
अतिसौरभ	३६
अतीक्ष्ण	१२२
अतीत	१३९
अतीतनौक	२६
अतीन्द्रिय	१०५
अतीव	१३८
अत्तिका	२१
अत्यंतकोपन	१०१
अत्यन्तीन	७९
अत्यय	६२
	१२७
अत्यर्थ	८
अत्यल्प	१०३
अत्याहित	१२०

	पृष्ठम्	श्लोकः
	११	२७
	१३७	२४७
	१३७	२४७
	१०३	६३
	११०	२२
न	१	८
	५९	६१
	७४	३०
	२३	३७
	१३९	१२
	२१	१७
	२१	१९
	९९	२०
	१२९	२०
	३३	१
	१२९	१६४
न्	२	१४
	१०३	५४
	१२७	१४५
	८३	५
	६१	९०
	१३१	१९०
व	४१	८८
	९९	११
	७७	६३
	७५	३१
	७२	६

शब्दः	पृष्ठम्	श्लोकः
अधिक्षिप्त	१०१	६२
अधित्यका	३२	७
अधिप	९९	११
अधिभू	९९	११
अधिरोहिणी	३२	१८
अधिवासन	६५	१३६
अधिविन्ना	५४	७
अधिश्रयणी	८५	२९
अधिष्ठान	१२५	१२६
अधीन	९९	१६
अधीर	१००	२६
अधीश्वर	७२	२
अधुना	१४०	२३
अधृष्ट	१००	२६
अधोंशुक	६४	११७
अधोक्षज	३	२१
अधोभुवन	२३	१
अधोमुख	१०१	३३
अध्यक्ष	७२ १३५	६ २२६
अध्यवसाय	२२	२९
अध्यात्म	१२७	१४४
अध्यापक	६७	७
अध्याहार	१५	३
अध्यूढा	५४	७
अध्येषणा	६९	३२

शब्दः	पृष्ठम्	श्लोक
अध्वग	७३	१९
अध्वन्	३०	१५
अध्वनीन	७३	१७
अध्वन्य	७३	१७
अध्वर	६७	१३
अध्वर्यु	६८	१७
अनक्षर	१९	२१
अनङ्ग	३	२६
अनच्छ	२६	१४
अनडुह्	८८	६०
अनन्त	२३ १२१	४ ८१
अनन्ता	२९ ४२ ४४ ४६ ४८	२ ९२ ११२ १३६ १५८
अनन्यज	३	२७
अनन्यवृत्ति	१०५	७९
अनय	१२७	१५०
अनर्थक	१९	२०
अनल	६	५८
अनवधानता	२२	३०
अनवरत	७	७०
अनवस्कर	१०३	५६
अनवरार्ध्य	१०३	५७
अनून	७६	५०

शब्दः	पृष्ठम्	श्लोकः
अनागतार्तवा	५४	८
अनातप	१२६	१५८
अनादर	२१	२२
अनामय	५८	५०
अनामिका	६१	८२
अनायासकृत	१०६	९४
अनारत	७	७०
अनार्यतिक्त	४६	१४३
अनाहत	६३	११२
अनिरुद्ध	३	२८
अनिल	२ ७	१० ६६
अनिश	७	७०
अनीक	७९	७८
अनीकस्थ	७२	६
अनीकिनी	७९ ७९	७८ ८१
अनु	१३७	२४८
अनुक	१००	२३
अनुकम्पा	२१	१८
अनुकर्ष	७७	५७
अनुकल्प	७०	४०
अनुकामीन	७९	७६
अनुकार	१०९	१७
अनुक्रम	७०	३७
अनुक्रोश	२१	१८
अनुग	१०५	७८
अनुग्रह	१०९	१३
अनुचर	७८	७१
अनुज	५७	४३
अनुजीविन्	७३	९
अनुतर्षण	९७	४३
अनुताप	२२ १२७	२५ १४८
अनुत्तम	१०३	५७
अनुत्तर	१३१	१९१
अनुनय	१३९	१८
अनुपद	१०५	७८
अनुपदीना	९६	३१
अनुपमा	९	४
अनुप्लव	७८	७१
अनुबन्ध	१२२	९८
अनुबोध	६४	१२२
अनुभव	११०	२७
अनुभाव	२१ १३३	२१ २१७
अनुमति	१३	८
अनुयोग	१७	१०
अनुरोध	७३	१२
अनुलाप	१८	१६
अनुलेपन	१४२	२३
अनुवर्तन	७३	१२
अनुवाक	१४१	१७
अनुशय	१२७	
अनुष्ण	९५	
अनुहार	१०९	
अनूक	११३	
अनूचान	६७	
अनूनक	१०४	
अनूप	३०	
अनूरु	१२	
अनृजु	१०२	
अनृत	१९ ८३	
अनेकप	७५	
अनेहस्	१२	
अनोकह	३४	
अन्त	८२ १०५	
अन्तःपुर	३२	
अन्तक	७	
अन्तर	१३१	
अन्तरा	१३८	
अंतराभवसत्त्व	१२६	
अन्तराय	११०	
अन्तराल	९	
अन्तरिक्ष	८	
अन्तरीप	२५	
अन्तरीय	६४	
अन्तरे	१३८	

पृष्ठम्	श्लोकः	शब्दः	पृष्ठम्	श्लोकः	शब्दः	पृष्ठम्	श्लोक
१३८	३	अन्यतर	१०५	८२	अपदिश	९	८
१३९	१०	अन्यतरेद्युस्	१३९	२१	अपदेश	२२	३३
१०५	८६	अन्येद्युस्	१३९	२१		१३४	२१३
१०	१२	अन्वक्	१०५	७८	अपध्वस्त	१०१	३९
३२	१४	अन्वक्ष	१०५	७८	अपभ्रंश	१७	२
९८	८	अन्वय	६६	१	अपयान	८२	१११
५५	२२	अन्ववाय	६६	१	अपरस्पर	१०८	१
९८	६	अन्वाहार्य	६९	३१	अपराजिता	४३	१०४
७२	८	अन्विष्ट	१०७	१०५		४७	१४९
येन् ९४	१०	अन्वेषणा	६९	३२	अपराद्धपृषत्क	७८	३८
१०४	६७	अन्वेषित	१०७	१०५	अपराध	७४	२६
१०४	६८	अप् (आपस्)	२५	३	अपराह्ण	१२	३
८५	२९	अपकारगिर्	१८	१४	अपरेद्युस्	१३९	२०
६७	११	अपक्रम	८२	१११	अपर्णा	५	४०
९५	२०	अपघन	६०	७०	अपलाप	१८	१७
५९	६६	अपचय	१०९	१६	अपवर्ग	१६	७
७५	४१	अपचायित	१०७	१०१	अपवर्जन	६९	३०
५९	६१	अपचित	१०७	१०१	अपवाद	१८	१३
१२३	१०३	अपचिति	६९	३५		१२९	८९
४	३७		११९	६७	अपवारण	१०	१२
२३	३	अपटु	५८	५८		१२५	१२
२३	३	अपत्य	५६	२८	अपशब्द	२१	२
८७	४८	अपत्रपा	२१	२३	अपष्ठु	१०५	८४
२७	२६	अपत्रपिष्णु	१००	२८	अपसद	९४	१६
८७	४८	अपथ	३०	१७	अपसर्प	७३	१३
१०८	१११	अपथिन्	३०	१७	अपसव्य	१०५	८४
१०५	८२	अपदान्तर	१०४	६८	अपस्कर	७७	५५

शब्दः	पृष्ठम्	श्लोकः
अपस्नात	९९	१९
अपहार	१०९	१६
अपांपति	२४	२
अपांग	६२ ११४	९४ २१
अपान	७ ६०	६८ ७३
अपामार्ग	४१	८८
अपावृत	९९	१५
अपासन	८२	११३
अपि	१३७	२४९
अपिधान	१०	१३
अपिनद्ध	७८	६५
अपूप	८७	४८
अपोगंड	५७	४६
अप्पति	७	६५
अप्पित्त	६	६०
अप्रकाण्ड	३४	९
अप्रगुण	१०४	७२
अप्रत्यक्ष	१०५	७९
अप्रधान	१०३	६०
अप्रहत	२९	५
अप्राग्र्य	१०३	६०
अप्सरस्	२ ६	११ ५६
अफल	३४	७
अबुद्ध	१९	२०

शब्दः	पृष्ठम्	श्लोकः
अबद्धमुख	१०१	३६
अबला	५३	२
अबाध	१०५	८३
अब्ज	१० ११६	१४ ३२
अब्जयोनि	२	१७
अब्द	१४ १२१ १२७	२० ८८ १४६
अब्धि	२४ १२३	१ १०१
अब्धिकफ	९२	१०५
अब्रह्मण्य	२०	१४
अभय	४८	१६४
अभया	३९	५९
अभाषण	६९	३६
अभिक	१००	२४
अभिक्रम	८०	९६
अभिख्या	१२८	१५६
अभिग्रह	१०९	१३
अभिग्रहण	१०९	१७
अभिघातिन्	७३	११
अभिचर	७८	७१
अभिचार	११०	१९
अभिजन	६६ १२३	१ १०८
अभिजात	१२१	८२

शब्दः	पृष्ठम्
अभिज्ञ	९८
अभितस्	१०४ १३७
अभिधान	१७
अभिध्या	२१
अभिनय	२१
अभिनव	१०५
अभिनवोद्भिद्	३४
अभिनिर्मुक्त	७१
अभिनिर्याण	८०
अभिनीत	७४ १२
अभिपन्न	१२५
अभिप्राय	११०
अभिभूत	१०१
अभिमर	१३३
अभिमान	२१ १२
अभियोग	१०९
अभिरूप	१२५
अभिलाव	११०
अभिलाष	२२
अभिलाषुक	१००
अभिवादक	१००
अभिवादन	७०
अभिव्याप्ति	१०८
आभिशस्त	१०२

	पृष्ठम्	श्लोकः
स्तित	६९	३२
प	१८	११
	११५	२४
	७१ ९७	४७ ४२
न	८०	९५
	१०८	११०
ात	८१	१०५
रिका	५४	१०
र	१०९ १२९	१७ १६८
त	१०७	१०७
	१००	२४
	१३८ १३९	१ ११
त	१०२ १०८	५३ ११२
	४३	१००
त्री	४३	१०१
	१०८	६
	१३४	२२०
	१०२	५३
	१०४	६७
र	९	६
त	५८	५८
त्रीण	७९	७५
त्रीय	७९	७५

शब्दः	पृष्ठम्	श्लोकः
अभ्यमित्र	७९	७५
अभ्यर्ण	१०४	६७
अभ्यर्हित	१२१	८३
अभ्यवकर्षण	१०९	१७
अभ्यवस्कन्दन	८२	११०
अभ्यवहृत	१०८	१११
अभ्याख्यान	१८	१०
अभ्यागम	८१	१०५
अभ्यागारिक	९९	१२
अभ्यादान	११०	२६
अभ्यान्त	५८	५८
अभ्यामर्द	८१	१०५
अभ्याश	१०४	६७
अभ्यासादन	८२	११०
अभ्युत्थान	६९	३४
अभ्युदित	७१	५५
अभ्युपगम	१५	५
अभ्युपपत्ति	१०९	१३
अभ्यूष	८७	४७
अभ्र	८ ९	१ ६
अभ्रक	९२	१००
अभ्रपुष्प	३६	३०
अभ्रमातङ्ग	६	५०
अभ्रमु	९	४
अभ्रमुवल्लभ	६	५०
अभ्रि	२६	१३

शब्दः	पृष्ठम्
अभ्रिय	९
अभ्रेष	७५
अमत्र	८६
अमर्	१
अमरावती	५
अमर्त्य	२
अमर्ष	२२
अमर्षण	१०१
अमा	१३७
अमांस	५७
अमात्य	७२
अमावस्या	१३
अमावास्या	१३
आमित्र	७३
अमुत्र	१३८
अमृणाल	४८
अमृत	६ १६ २५ ६९ ८३ १२०
अमृता	३९ ३९ ४१
अमृतान्धस्	२
अमोघा	४३

ब्दः	पृष्ठम्	श्लोकः
म्बर	८	१
	१३०	१८२
म्बरीष	८५	३०
म्बष्ठ	९३	२
म्बष्ठा	४०	७१
	४१	८४
	४६	१४०
अम्बा	२१	१४
अम्बिका	५	४०
अम्बु	२५	४
अम्बुकण	१०	११
अम्बुज	३९	६१
अम्बुभृत्	९	७
अम्बुवेतस्	३६	३०
अम्बुसरण	२५	११
अम्बूकृत	१९	२०
अम्भस्	२५	४
अम्भोरुह	२८	४१
अम्मय	२५	५
अम्ल	१६	९
अम्ललोणिका	४६	१४०
अम्लवेतस	४६	१४१
अम्लान	४०	७३
अम्लिका	३७	४३
अय	१५	२७
अयन	१३	१३
	३०	१५

शब्दः	पृष्ठम्	श्लोकः
अयस्	९२	९८
अयःप्रतिमा	९६	३५
अयाचित	८३	३
अयि	१३९	१८
अयोग्र	८५	२५
अयोघन	११६	३७
अर	७	६९
अरघट्ट	१४१	१८
अरणि	६८	१९
अरण्य	३४	१
	१४२	२२
अरण्यानी	३४	१
अरत्नि	६१	८६
अरर	३२	१७
अरलु	३९	५७
अरविंद	२८	३९
अराति	७३	११
अराल	१०४	७१
अरि	७३	१०
अरित्र	२५	१३
अरिमेद	३८	५०
अरिष्ट	३१	८
	३६	३१
	३९	६२
	४७	१४८
	५१	२०
	८८	५३
	११६	३६

शब्दः	पृष्ठम्
अरिष्टदुष्टधी	१०२
अरुण	११
	१२
	१६
	११७
अरुणा	४२
अरुंतुद	१०५
अरुष्कर	३७
	१३१
अरुस्	५८
अरोक	१०७
अर्क	११
	११२
अर्कपर्ण	४१
अर्कबन्धु	२
अर्काह्व	४१
अर्गल	३२
अर्घ	११५
अर्घ्य	६९
अर्चा	६९
	९६
अर्चित	१०७
	१२१
अर्चिस्	७
	१३५
अर्जक	४१

	पृष्ठम्	श्लोकः	शब्दः	पृष्ठम्	श्लोकः	शब्दः	पृष्ठम्
	१६	१३	अर्धोरुक	६४	११९	अलंकरिष्णु	६२
	३८	४५	अर्बुद	१४२	१९		१००
	४९	१६७		१४३	३३	अलंकर्तृ	६२
	८९	६७	अर्भक	५३	३८	अलंकर्मीण	९९
	२५	७	अर्म	१४३	३४	अलंकार	६२
	११८	५७	अर्य	८३	१	अलंकृत	६२
	२५	४		१२७	१४७	अलंक्रिया	६२
	१११	३२	अर्यमन्	११	२८	अलम्	१३७
	११९	६८	आर्या	५४	१४		१३९
	९१	९०	अर्याणी	५४	१४	अलर्क	४१
	१२१	८६	अर्यी	५४	१५		९५
	६९	३२	अर्वन्	७६	४४	अलस	९५
	१०८	६		१०३	५४	अलात	८५
ग	८३	४	अर्वाक्	२५	७	अलाबू	४८
त्र	१७	७		१३९	१६	आलि	५०
	७३	८	अर्शस्	५८	५४		५२
	१०२	५९	अर्शस	५८	५९		१३२
	९२	१०४				अलिक	६२
	१२८	१६०	अर्शोघ्न	४८	१५७	अलिंजर	८६
	१०८	६	अर्शोरोगयुत	५८	५९	अलीक	११३
	१०६	९७	अर्हण	६९	३५	अल्प	१०३
	१०	१६	अर्हित	१०७	१०१	अल्पमारिष	४६
ा	४३	१०९	अलक	६२	९६	अल्पसरस्	२७
	२६	१४	अलका	८	७५	आल्पिष्ठ	१०३
	१३	६	अलक्त	६५	१२५	अल्पीयस्	१०३
	१४३	३२	अलक्ष्मी	२४	२	अवकर	३२
	६३	१०६	अलगर्द	२३	५	अवकीर्णिन्	७१

:	पृष्ठम्	श्लोकः
ृष्ट	१०१	३९
काशिन्	३४	७
क्रय	९०	१९
ाणित	१०७	१०६
गत	१०७	१०८
गीत	१०६ १२०	९३ ५९
ग्रह	९ ६५	११ ३८
ग्राह	९	११
चूर्णित	१०६	९४
ज्ञा	२१	२३
ज्ञात	१०७	१०६
वट	२३	२
वटीट	५७	४५
वटु	६१	८८
वतंस	१३५	२२८
वतमस	२३	३
वतोका	८९	६९
वदंश	९७	४०
वदात	१६ १२०	१३ ८०
वदान	१०८	३
वदाह	४८	१६५
वदारण	८४	१२
वदीर्ण	१०६	८९

शब्दः	पृष्ठम्	श्लोकः
अवद्य	१०३	५४
अवधारण	१३०	१७८
अवधि	१२२	९९
अवध्वस्त	१०६	९४
अवन	१०८	४
अवनत	१०४	७०
अवनाट	५७	४५
अवनाय	११०	२७
अवनि	२९	३
अवन्तिसोम	८६	३९
अवन्ध्य	३४	६
अवभृथ	६९	२७
अवभ्रट	५७	४५
अवम	१०३	५४
अवमत	१०७	१०६
अवमर्द	८२	१०९
अवमानना	२१	२३
अवमानित	१०७	१०६
अवयव	६०	७०
अवर	७५	४०
अवरज	५७	४३
अवरति	१११	३८
अवरवर्ण	९३	१
अवरीण	१०६	९४
अवरोध	३२	१२
अवरोधन	३२	११

शब्दः	पृष्ठम्
अवरोह	३४
अवर्ण	१८
अवलक्ष	१६
अवलग्न	६०
अवलंबित	१२३
अवल्गुज	४२
अववाद	७४
अवश्यम्	१३९
अवश्याय	१०
अवष्टब्ध	१२३
अवसर	११०
अवसान	१११
अवसित	१०७ १०७
अवस्कर	५९ १२९
अवस्था	१५
अवहार	२६
अवहित्था	२२
अवहेलन	२१
अवाक्	९९ १०१
अवाक्पुष्पी	४७
अवाग्र	१०४
अवाची	८
अवाच्य	१९
अवार	२५

:	पृष्ठम्	श्लोकः
सस्	१०१	३९
	५५	२०
	१३३	२०७
म्र	८०	६७
त	१०७	१०६
या	१६	७
नीत	१००	२३
रत	७	७०
लम्बित	७	६९
	१०५	८३
स्पष्ट	१९	२१
चि	२४	१
रा	५४	११
ज्ञा	११०	२८
क्त	११९	६२
क्तराग	१६	१५
ण्डा	४१	८६
था	३९	५९
	४७	१४६
य	१४३	३४
वहित	१०४	६८
नाया	८८	५४
नायित	९९	२०
नि	६	५१
त	१०८	१११
श्वी	५४	११

शब्द	पृष्ठम्	श्लोकः
अशुभ	१४२	२३
अशेष	१०४	६५
अशोक	३९	६४
अशोकरोहिणी	४१	८५
अश्मगर्भ	९१	९२
अश्मज	९२	१०४
अश्मन्	३३	४
अश्मन्त	८५	२९
अश्मपुष्प	४५	१२२
अश्मरी	५८	५६
अश्मसार	९२	९८
अश्रान्त	७	७०
अश्रि	८०	९३
अश्रु	६२	९३
अश्लील	१८	१९
अश्व	७६	४३
अश्वकर्णक	३७	४४
अश्वत्थ	३५	२१
अश्वयुग्	१०	२१
अश्ववडव	१४१	१६
अश्वा	७६	४६
अश्वाभिरण	१७७	४४
अश्वारोह	७७	६०
अश्विन्	६	५५
अश्विनी	१०	२१
अश्विनीसुत	६	५५
अश्वीय	७८	४८

शब्दः	पृष्ठम्
अषडक्षीण	७४
अष्टापद	९१
	९७
अष्ठीवत्	६०
असकृत्	१३८
असती	५४
असतीसुत	५५
असन	३७
असमीक्ष्यकारिन्	९९
असार	१०३
असि	८०
असिक्नी	५५
असित	१६
असिधात्रक	९४
असिधेनुका	८०
असिपुत्री	८०
असु	८३
असुधारण	८३
असुर	२
असूर्क्षण	२१
असूया	२१
असृग्धरा	५९
असृज्	५९
असौम्यस्वर	१०१
अस्त	३३
	१०६
अस्तम्	१३९

ः	पृष्ठम्	श्लोकः
ित	१३९	१८
तु	१३९	१३
त्र	७९	८२
स्थि	५९	६८
स्थिर	१०२	४३
स्फुटवाच्	१०१	३७
स्र	५९	६४
	६२	९३
	१२९	१६५
स्वप	७	६३
स्रु	६२	९३
स्वच्छन्द	९९	१६
स्वप्न	२	८
स्वर	१०१	३७
स्वाध्याय	७१	५४
अहंयुस्	१०२	५०
अहंकार	२१	२२
अहंकारवान्	१०२	५०
अहन्	१२	२
अहमहमिका	८१	१०१
अहम्पूर्विका	८१	१००
अहम्मति	१६	७
अहर्पति	११	३०
अहर्मुख	१२	२
अहस्कर	११	२८
अहह	१३८	२५७
अहार्य	३३	१

शब्दः	पृष्ठम्	श्लोकः
अहि	२३	६
	१३६	२३९
अहित	७३	११
अहितुण्डिक	२४	११
अहिभय	७४	३०
अहिभुज्	११५	३०
अहेरु	४३	१०१
अहो	१३८	९
अहोरात्र	१३	१२
अह्नाय	१३८	२
आ		
आ	१३६	२४०
आं	१३९	१६
आकम्पित	१०६	८७
आकर	३३	७
आकर्ष	१३४	२२२
आकल्प	६२	९९
आकार	१०९	१५
	१२९	१६३
आकारगुप्ति	२२	३४
आकारण	१७	८
आकाश	८	२
आकीर्ण	१०५	८५
आकुल	१०४	७२
आकृति	१२९	१६३
आक्रन्द	१२२	९०
आक्रीड	३४	३

शब्दः	पृष्ठम्
आक्रोश	१८
आक्रोशन	१०८
आक्षारणा	१७
आक्षारित	१०२
आक्षेप	१८
आखण्डल	५
आखु	५०
आखुभुज्	५०
आखेट	९५
आख्या	१७
आख्यात	१०७
आख्यायिका	१७
आगन्तु	६९
आगम	३४
आगस्	७४
	१३५
आगू	१५
आग्नीध्र	६८
आग्रहायणिक	१३
आग्रहायणी	११
आङ्	१३६
आह्निक	२१
आङ्गिरस	११
आचमन	६९
आचाम	८७
आचार्य	६७
आचार्या	५४

	पृष्ठम्	श्लोकः
र्यनी	५४	१५
त	९१	८७
छादन	१०	१३
	६४	११५
ुरितक्क	२२	३४
ोदन	९५	२३
क	९०	७७
नेय	७६	४४
	८१	१०६
	११६	३२
त्र	८३	१
	२४	३
	७४	२६
त्र	८८	५२
	५१	२५
	८२	१०८
स्वर	११९	१६८
	५१	२५
	९१	८८
केक	८४	१०
की	४५	१३०
	१४०	७
	९९	१०
हं	११३	१०
न	१२४	११५
ायिन	१०२	४४

शब्दः	पृष्ठम्	श्लोकः
आतप	१२	३४
	१४२	२०
आतपत्र	७५	३२
आतर	२५	११
आतापिन्	५९	२१
आतिथेय	६९	३३
आतिथ्य	६९	३३
आतुर	५८	५८
आतोद्य	२०	५
आत्तगर्व	१०१	४०
आत्मगुप्ता	४१	८६
आत्मघोष	५१	२०
आत्मज	५६	२७
आत्मन्	१५	२९
	१२३	१०९
आत्मभू	२	१६
	३	२७
आत्मम्भरि	१००	२१
आत्रेयी	५५	२०
आथर्वण	११२	४३
आदर्श	६६	१४०
आदि	१०५	८०
आदिकारण	१५	२८
आदितेय	१	८
आदित्य	२	८
	२	१०
	११	२८

शब्दः	पृष्ठम्
आदीनव	१११
अ दृत	१२१
आदेष्टा	६७
आद्य	१०५
आद्यमाषक	९१
आद्यून	१००
आद्योत	११२
आधार	२७
आधि	२२
	१२२
आधूत	१०६
आधोरण	७७
आध्यान	२२
आनक	२०
	११२
आनकदुन्दुभि	३
आनत	१०४
आनद्ध	२०
आनन	६१
आनंद	१४
आनन्दथु	१४
आनन्दन	१०९
आनर्त	११९
आनाय	२६
आनाय्य	६८
आनाह	५८
आनपूर्वी	७०

शब्दानुक्रमणिका.

ः	पृष्ठम्	श्लोकः
ान्धसिक	८५	२८
ान्वीक्षिकी	१७	५
ापक्क	८७	४७
ापगा	२७	३०
ापण	३१	२
ापणिक	९०	७८
ापत्प्राप्त	१०१	४२
ापद्	७९	८२
ापन्न	१०१	४२
ापन्नसत्वा	५५	२२
ापमित्यक	८३	४
ापान	९७	४३
ापीड	६६	१३६
ापीन	८९	७३
ापूपिक	८५ ११२	२८ ४०
ाप्त	७३	१३
ाप्य	२५	५
ाप्यायन	१२४	११५
ाप्रच्छन्न	१०९	७
ाप्रपद	६४	११९
ाप्रपदीन	६४	११९
ाप्लव	६४	१२१
ाप्लाव	६४	१२१
ाबन्ध	८४	१३
ाभरण	६२	१०१

शब्दः	पृष्ठम्	श्लोकः
आभाषण	१८	१५
आभास्वर	२	१०
आभीर	८८	५७
आभीरपल्ली	३३	२०
आभीरी	३४	१३
आभील	२४	४
आभोग	६६	१३७
आमगन्धिन्	१६	१२
आमनस्य	२४	३
आमय	५८	५१
आमयाविन्	५८	५८
आमलक	१४३	३३
आमलकी	३९	५७
आभिक्षा	६८	२२
आमिष	५९ १३४	६३ २२४
आमिषाशिन्	९९	१९
आमुक्त	७८	६५
आमोद	१४ १६ १२२	२४ १० ९१
आमोदिन्	१६	११
आम्नाय	१७ १०९	३ ७
आम्र	३६	३३
आम्रातक	३६	२७
आम्रेडित	१८	१२

शब्दः	पृष्ठम्
आयत	१०४
आयतन	३१
आयति	७४ १२०
आयत्त	९९
आयाम	६४
आयुध	७९
आयुधिक	७८
आयुधीय	७८
आयुष्मत्	९८
आयुस्	८३
आयोधन	८१
आरकूट	९२
आरग्वध	३६
आरनालक	८६
आरति	१११
आरंभ	११०
आरव	१९
आरा	९६
आरात्	१३६
आराधन	१२५
आराम	३४
आरालिक	८५
आराव	१९
आरेवत	३६
आरोग्य	५८
आरोह	६४ १३६

	पृष्ठम्	श्लोकः
ण	३२	१८
ल	४०	७४
	५५	२१
	१०७	१०५
	८६	३७
	६६ २१	३ १४
	५	४१
र्त	३०	८
य	८८	६२
	९२	१०२
म	८२	११५
	३१	[illegible]
ाल	२७	२९
	९५	१८
	७५	४१
	१८	१५
	३० ३४ ५४	१४ ४ १२
्य	२०	५
द	३२	१२
	१३२	१९८
	७९	८५
	८६	३१
क	११२	३
कन	१११	३१

शब्दः	पृष्ठम्	श्लोकः
आवपन	८६	३३
आवर्त	२५	६
आवलि	३४	४
आवसित	८५	२३
आवाप	२७	२९
आवापक	६३	१०७
आवाल	२७	२९
आविद्ध	१०४ १०६	७१ ८७
आविध	१११	३६
आविल	२६	१४
आविस्	१३९	१२
आवुक	२०	१२
आवुत्त	२०	१२
आवृत्	७०	३७
आवृत	१०६	९०
आवेगी	४६	१३७
आवेशन	३१	७
आवेशिक	६९	३४
आशंसित	१००	२७
आशंसु	१००	२७
आशय	११०	२०
आशर	७	६३
आशा	८ १३४	१ २१७
आशितंगवीन	८८	५९
आशीविष	२३	७

शब्दः	पृष्ठम्
आशीस्	१३५
आशु	७ ८४
आशुग	८० ११४
आशुव्रीहि	८४
आशुशुक्षणि	६
आश्चर्य	२१
आश्रम	६६
आश्रय	१०९
आश्रयाश	६
आश्रव	१५ १००
आश्रुत	१०७
आश्व	७६
आश्वयुज्	१४
आश्विन	१४
आश्विनेय	६
आश्वीन	७६
आषाढ	१४ ७०
आसक्त	९८
आसन	६६ ७३ ७५
आसना	११०
आसन्दी	१४१

शब्दः	पृष्ठम्	श्लोकः
आसन्न	१०४	६६
आसन्न	९७	४२
आसादित	१०७	१०४
आसार	१०	११
	८०	९६
आसुरी	८४	१९
आसेचनक	१०२	५३
आस्कन्दन	८१	१०४
आस्कन्दित	७६	४८
आस्तरण	७६	४२
आस्था	१२१	८८
आस्थान	६७	१५
आस्थानी	६७	१५
आस्पद	१२२	९४
आस्फोट	४१	८०
आस्फोटनी	९६	३४
आस्फोटा	४०	७०
	४३	१०४
आस्य	६१	८९
आस्या	११०	२१
आस्रव	१११	२९
आहत	१९	२१
	१०६	८८
आहतलक्षण	९९	१०
आहव	८१	१०५
आहवनीय	६८	१९
आहार	८८	५६

शब्दः	पृष्ठम्	श्लोकः
आहाव	२७	२६
आहेय	२४	९
आहो	१३८	५
आहोपुरुषिका	८१	१०१
आह्वय	१७	७
आह्वा	१७	८
आह्वान	१७	८
	इ	
इक्षु	४८	१६३
इक्षुगन्धा	४२	९८
	४३	१०४
	४३	११०
	४८	१६३
इक्षुर	४३	१०४
इक्ष्वाकु	४८	१५६
इङ्ग	१०४	७४
	१०९	१५
इङ्गित	१०९	१५
इङ्गुदी	३८	४६
इच्छा	२२	२७
इच्छावती	५४	९
इज्याशील	६७	८
इट्चर	८८	६२
इडा	११७	४२
इतर	९४	१६
	१०५	८२
	१३१	९२
इतरेद्युस्	१३९	२१

शब्दः	पृष्ठम्
इति	१३७
इतिह	६७
इतिहास	१७
इत्वरी	५४
इदानीम्	१४०
इध्म	३५
इन	१२४
इन्दीवर	२८
इन्दीवरी	४३
इन्दु	१०
इन्द्र	५
	९
इन्द्रद्रु	३८
इन्द्रयव	४०
इन्द्रवारुणी	४८
इन्द्रसुरस	४०
इन्द्राणिका	४०
इन्द्राणी	५
इन्द्रायुध	९
इन्द्रारि	२
इन्द्रावरज	३
इन्द्रिय	१६
	५९
इन्द्रियार्थ	१६
इन्धन	३५
इभ	७५
इभ्य	९९

	पृष्ठम्	श्लोकः
	९	१०
	९७	४०
	१३०	१७६
	११७	४२
	११	२३
	१३८	९
	१४	१७
	८०	८७
	८०	८८
	६९	२८
	८८	५७
य	४८	१६५
	१६	११
त्त	९८	९
	११६	३९
	७९	८३
	ई	
	६२	९३
	१११	३१
ा	५५	२०
	१०८	११०
	११९	६८
	११८	५७
	१०६	८७
	५८	५४
	२१	२४
	१०८	१०९

शब्दः	पृष्ठम्	श्लोकः
ईली	८०	९१
ईश	४	३३
	९	३
ईशान	४	३३
ईशितृ	९९	१०
ईश्वर	४	३३
	९९	१०
ईश्वरी	५	३९
ईषत्	१३८	८
ईषत्पाण्डु	१६	१३
ईषा	८४	१४
ईषिका	७५	३८
	९६	३३
ईहा	२२	२७
ईहामृग	५०	७
	उ	
उ	१३९	१८
उक्त	१०७	१०७
उक्ति	१७	१
उकथ	१४३	३०
उक्षन्	८८	५९
उखा	८६	३१
उख्य	८७	४५
उग्र	४	३५
	२१	२०
	९३	२

शब्दः	पृष्ठम्	श्लो
उग्रगन्धा	४३	१
	४७	१
उच्च	१०४	
उच्चटा	४८	१
उच्चण्ड	१०५	
उच्चार	५९	
उच्चावच	१०५	
उच्चैःश्रवस्	५	
उच्चैर्घुष्ट	१८	
उच्चैस्	१३९	
उच्छ्रय	३४	
उच्छ्राय	३४	
उच्छ्रित	१०४	
	१२१	
उज्ञासन	८२	१
उज्ज्वल	२१	
उञ्छशिल	८३	
उटज	३१	
उडु	१०	
उडुप	२५	१
उड्डीन	५२	३
उत	१०७	१०
	१३६	२४
	१३८	
उताहो	१३८	
उत्क	९८	
उत्कट	४६	१
	१००	

शब्दः	पृष्ठम्	श्लोकः
उत्कण्ठा	२२	२९
उत्कर	५३	४२
उत्कर्ष	१०९	११
उत्कलिका	२२	२९
उत्कार	१११	३६
उत्क्रोश	५१	२३
उत्त	१०७	१०५
उत्तंस	१३५	२२८
उत्तप्त	५९	६३
उत्तम	१०३	५७
उत्तमर्ण	८३	५
उत्तमा	५३	४
उत्तमाङ्ग	६२	९५
उत्तर	१७ १३१	१० १९१
उत्तरा	८	२
उत्तरासङ्ग	६४	११७
उत्तरीय	६४	११८
उत्तरेद्युस्	१३९	२०
उत्तान	२६	१५
उतानशय	५७	४१
उत्थान	१२४	११८
उत्थित	१२१	८५
उत्पतितृ	१००	२९
उत्पत्ति	१५	३८
उत्पतिष्णु	१००	२९
उत्पन्न	१२१	८५
उत्पल	२८ ४५	३७ १२६
उत्पलशारिवा	४४	११२
उत्पात	८२	१०९
उत्फुल्ल	३४	७
उत्स	३३	५
उत्सर्जन	६९	२९
उत्सव	२३ १३३	३८ २०९
उत्सादन	६४	१२१
उत्साह	२२ ७३	२९ १९
उत्साहन	१२४	११५
उत्साहवर्धन	२१	१८
उत्सुक	९८	९
उत्सृष्ट	१०७	१०७
उत्सेध	३४ १२२	१० ९६
उदक्	१४०	२३
उदक	२५	४
उदक्या	५५	२१
उदग्र	१०४	७०
उदज	१११	३९
उदधि	२४	१
उदन्त	१७	७
उदन्या	८८	५५
उदन्वत्	२४	५

शब्दः	पृष्ठम्
उदपान	२७
उदय	३३
उदर	६०
उदर्क	७४
उदवसित	३१
उदश्वित्	८८
उदात्त	१७
उदान	७
उदार	९८ १३१
उदासीन	७३
उदाहार	१७
उदित	१०७
उदीची	८
उदीच्य	३० ४५
उदुम्बर	३५ ९२
उदुम्बरपर्णी	४७
उदूखल	८५
उद्गत	१०६
उद्गमनीय	६३
उद्गाढ	८
उद्गातृ	६८
उद्गार	१११
उद्गीथ	१४१
उद्गूर्ण	१०६

पृष्ठम्	श्लोकः
१११	३७
१४	२७
१११	३५
९५	२७
११०	२६
७४	२६
३७	३४
१०६	९५
८२	१११
२३	३८
२३	३८
८५	२९
८३	४
१०६	९०
१५	३८
१०२	५१
१०२	५१
१०२	५१
१०९	१२
१०६	८९
१०९	११
१२४	११७
१४३	३३
२६	२०
६४	१२१
७५	३६
१०६	९७

शब्दः	पृष्ठम्	श्लोकः
उद्वासन	८२	११५
उद्वाह	७२	५७
उद्वेग	४९	१६९
	१०९	१२
उन्दुरु	५०	१२
उन्नत	१०४	७०
उन्नतानत	१०४	६९
उन्नद्ध	१२१	८५
उन्नय	१०९	१२
उन्नाय	१०९	१२
उन्मत्त	४०	७७
	५९	६०
उन्मदिष्णु	१००	२३
उन्मनस्	९८	८
उन्माथ	८२	११५
	९५	२६
उन्माद	२२	२६
	१००	२३
उन्मादवत्	५९	६०
उपकण्ठ	१०४	६७
उपकारिका	३२	१०
उपकार्य	३२	१०
उपकुञ्चिका	४५	१२५
	८६	३७
उपकुल्या	४२	९६
उपक्रम	६७	१३
	१२६	१३९
	११०	२६

शब्दः	पृष्ठम्
उपक्रोश	१८
उपगत	१०८
उपगूहन	१११
उपग्रह	८३
उपग्राह्य	७४
उपघ्न	११०
उपचरित	१०७
उपचाय्य	६८
उपचित	१०६
उपचित्रा	४१
उपजाप	७४
उपज्ञा	६७
उपतप्तृ	१०९
उपताप	५८
उपत्यका	३३
उपदा	७४
उपधा	७४
उपधान	६६
उपधि	२२
उपनाह	२०
उपनिधि	९०
उपनिषद्	१२२
उपनिष्कर	३१
उपन्यास	१७
उपपति	५६
उपबर्ह	६६

दः	पृष्ठम्	श्लोकः	शब्दः	पृष्ठम्	श्लोकः	शब्दः	पृष्ठम्
पभृत्	६८	२५	उपश्रुत	१०८	१०९	उपानह्	९६
पभोग	११०	२०	उपसंख्यान	६४	११७	उपाय (चतुष्टय)	७४
पमा	९६	३६	उपसंपन्न	६८	२६	उपायन	७४
	९६	३८		८७	४५	उपालम्भ	१८
पमात्	१३०	१७७	उपसर	११०	२५	उपावृत्त	७६
पमान	९६	३६	उपसर्ग	८२	१०९	उपासंग	८०
पयम	७१	५६	उपसर्जन	१०३	६०	उपासन	८०
पयाम	७२	५७	उपसर्या	८९	७०	उपासना	६९
परक्त	१३	१०	उपसूर्यक	१२	३२	उपासित	१०७
	१०२	४३	उपस्कर	८६	३५	उपाहित	१३ १०६
परक्षण	७५	३३	उपस्थ	६०	७५		
पराग	१३	९	उपस्पर्श	६९	३६	उपेन्द्र	३
पराम	१११	३८	उपहार	७४	२८	उपोदिका	४८
पारि	१३१	१८४	उपह्वर	१३१	१८३	उपोद्घात	१७
पल	३३	४	उपांशु	७४	२३	उपक्रुष्ट	८३
पलब्धार्था	१७	५	उपाकरण	७०	४१	उभयद्युस्	१४०
पलब्धि	१५	१	उपाकृत	६८	२५	उभयेद्युस्	१४०
पलम्भ	११०	२७	उपात्यय	७०	३७	उमा	५
पला	१३२	२००		१११	३३		८५
पवन	३४	२	उपादान	१०९	१६	उमापति	४
पवर्तन	३०	८	उपाधि	२२	२८	उरःसूत्रिका	६३
पबर्ह	६६	१३७		९९	१२	उरग	२४
पवास	७०	३८	उपाध्याय	६७	७	उरण	९०
पविषा	४२	९९	उपाध्याया	५४	१४	उरणाख्य	४७
पवीत	७१	५०	उपाध्यायानी	५४	१५	उरभ्र	९०
पशल्य	३३	२०	उपाध्यायी	५४	१४	उररी	१३७
पशाय	१११	३२		५४	१५	उररीकृत	१०७

	पृष्ठम्	श्लोकः
	७८	६४
	६०	७८
	७९	७६
	५६	२८
	७९	७६
	१०३	६१
	३८	५१
	२९	४
	६	५६
	२९	३
	४८	१५५
	३४	९
	५०	१५
	८५	२५
क	३७	३४
	२६	१८
	१४०	८
	५७	३८
	१०५	८१
	८५	३०
	५८	५७
	६४	१२०
	२५	६
	११	२५
	४८	१६४
	४२	९७

शब्दः	पृष्ठम्	श्लोकः
उषर्बुध	६	५८
उषस्	१२	२
उषा	१३९	१८
उषापति	३	२८
उषित	१०७	९९
उष्ट्र	९०	७५
उष्ण	१४	१९
	९५	१९
उष्णरश्मि	११	२९
उष्णिका	८७	५०
उष्णीष	१३४	२२०
उष्णोपगम	१४	१९
उष्मक	१४	१८
उस्र	१२	३३
उस्रा	८९	६६

ऊ

शब्दः	पृष्ठम्	श्लोकः
ऊत	१०७	१०१
ऊधस्	८९	७३
ऊन	१२५	१२८
ऊम्	१३९	१८
ऊररी	१३७	२५४
ऊरव्य	८३	१
ऊरी	१३७	२५४
ऊरीकृत	१०७	१०८
ऊरु	६०	७३
ऊरुज	८३	१
ऊरुपर्वन्	६०	७२

शब्दः	पृष्ठम्	श्लो
ऊर्ज	१४	
ऊर्जस्वल	७९	
ऊर्जस्विन्	७९	
ऊर्णनाभ	५०	
ऊर्णा	११८	
ऊर्णायु	९३	१
ऊर्ध्वक	२०	
ऊर्ध्वजानु	५७	४
ऊर्ध्वज्ञ	५७	४
ऊर्मि	२५	
ऊर्मिका	६३	१०
ऊर्मिमत्	१०४	७
ऊष	२९	
ऊषण	८६	३
ऊषर	२९	
ऊषवत्	२९	
ऊष्मागम	१४	१
ऊह	१५	

ऋ

शब्दः	पृष्ठम्	श्लो
ऋक्थ	९१	९
ऋक्ष	१०	२
	३९	५
	४९	
ऋक्षगन्धा	४६	१३
ऋक्षगन्धिका	४२	११
ऋच्	१७	
ऋजीष	८६	३

शब्दानुक्रमणिका.

शब्दः	पृष्ठम्	श्लोकः
ऋजु	१०४	७२
ऋजुरोहित	९	१०
ऋण	८३	३
ऋत	१९ ८३	२२ २
ऋतीया	१११	३२
ऋतु	१३ ११९	१३ ६१
ऋतुमती	५५	२१
ऋते	१३८	३
ऋत्विज	६८	१७
ऋद्ध	८५	२३
ऋद्धि	४४	११२
ऋभु	२	८
ऋभुक्षिन्	५	४८
ऋश्य	५०	१०
ऋषभ	१९ ४४ ८८ १०३	१ ११६ ५९ ५९
ऋषि	७०	४३
ऋष्यकेतु	३	२८
ऋष्यप्रोक्ता	४१ ४३	८७ १०१
ए		
एकं	१०५ ११३	८२ १६

शब्दः	पृष्ठम्	श्लोकः
एकक	१०५	८२
एकगुरु	६७	१२
एकतान	१०५	७९
एकताल	१९	३
एकदन्त	५	४२
एकदा	१४०	२२
एकधुर	८९	६५
एकधुरावह	८९	६५
एकधुरीण	८९	६५
एकपदी	३०	१५
एकपिङ्ग	८	७४
एकयष्टिका	६३	१०६
एकसर्ग	१०५	८०
एकहायनी	८९	६८
एकाकिन्	१०५	८२
एकाग्र	१०५ १३१	७९ १९०
एकाग्र्य	१०५	८०
एकान्त	८	७१
एकाब्दा	८९	६८
एकायन	१०५	७९
एकायनगत	१०५	८०
एकावली	६३	१०६
एकाष्ठील	४१	८१
एकाष्ठीला	४१	८५
एड	५७	४८
एडक	९०	७६

शब्दः	पृष्ठम्
एडगज	४७
एडमूक	१०१
एडूक	३१
एण	५०
एत	१७
एतर्हि	१४०
एध	३५
एधस्	३६
एधा	१०९
एधित	१०५
एनस्	१४
एरण्ड	३८
एला	४५
एलापर्णी	४६
एलावालुक	४४
एव	१३८
एवम्	१३८ १३९ १३९ १३९
एषणिक	९६
ऐ	
ऐकागारिक	९५
ऐंगुद	३५
ऐण	५०
ऐणेय	५०
ऐतिह्य	६७

	पृष्ठम्	श्लोकः
	१०५	७९
	६	५०
	६ ९ ३७	५० ३ ३८
	९	९
	८	७४
	४४	१२१
	४	३९
	१३९	२०
	ओ	
	१३५	२३३
	२० ५२ ११५	९ ३९ २७
	१७	४
	१३५	२३
	४०	७६
	५०	६
	८७	४८
	१३९	१२
	१०९	९
	३४	६
	१०	१४
	६१	९०
	औ	
	८८	६०

शब्दः	पृष्ठम्	श्लोकः
औचिती	१४३	३९
औचित्य	१४३	३९
औत्तानपादि	१०	२०
औत्सुक्य	१३५	२२९
औदनिक	८५	२८
औदरिक	१००	२१
औपगवक	१११	४०
औपयिक	७४	२४
औपवस्त	७०	३८
औरभ्रक	९०	७७
औरस	५६	२८
और्ध्वदेहिक	६९	३०
और्व	६	६०
औशीर	१३१	१८६
औषध	४६ ५८	१३५ ५०
औष्ट्रक	९०	७७
	क	
क	११२	५
कंस	८६	३२
कंसाराति	३	२१
ककुद	१२२	९२
ककुद्मती	६०	७४
ककुन्दर	६०	७५
ककुभ्	८ २० ३८	१ ७ ४५

शब्दः	पृष्ठम्	श्लो
कक्ष	६० १३४	
कक्ष्या	७६ १२८	
कङ्क	५१	
कङ्कटक	७८	
कङ्कण	६३	
कङ्कतिका	६३	
कङ्काल	५९	
कङ्कोलक	६५	
कंगु	८५	
कच	६२	
कच्चर	१०३	
काच्चित्	१३९	
कच्छ	३० ४५	
कच्छप	२६	
कच्छपी	१२५	
कच्छुर	५८	
कच्छुरा	५२	
कच्छू	५८	
कञ्चुक	२४ ६७	
कञ्चुकिन्	७२	
कट	६० ६५ ८५ ११६	

शब्दः	पृष्ठम्	श्लोकः
कटक	३३ ६३	५ १०७
कटभी	४७	१५०
कटम्भरा	४१ ४७	८५ १५३
कटाक्ष	६२	९४
कटाह	१४२	२१
कटि	६०	७४
कटिप्रोथ	६०	७५
कटी	१४३	३८
कटु	१६ ४१ ११६	९ ८५ ३५
कटुतुम्बी	४८	१५६
कटुरोहिणी	४१	८५
कट्फल	३७	४०
कट्वङ्ग	३९	५६
कठिंजर	४१	७९
कठिन	१०५	७६
कठिल्लक	४७	१५४
कठोर	१०५	७६
कडङ्गर	८५	२२
कडम्ब	८६	३५
कडार	१६	१६
कण	१०३ ११७	६२ ४५
कणा	४२ ८६	९६ ३६

शब्दः	पृष्ठम्	श्लोकः
कणिका	३९	६६
कणिश	८५	२१
कण्टकारिका	४२	९३
कण्टकिफल	३९	६१
कण्ठ	६१	८८
कण्ठभूषा	६३	१०४
कण्डुरा	४१	८६
कण्डू	५८	५३
कण्डूया	५८	५३
कण्डोल	८५	२६
कण्डोलविणा	९६	३२
कत्तृण	४९	१६६
कथा	१७	६
कदध्वन्	३०	१६
कदम्ब	३७	४२
कदम्बक	५३	४०
कदर	३८	५०
कदर्य	१०२	४८
कदली	४४ ५०	११३ ९
कदाचित्	१३८	४
कदुष्ण	१२	३५
कद्रु	१६	१६
कद्वद	१०१	३७
कनक	९१	९४
कनकाध्यक्ष	७२	७
कनकालुका	७५	३२

शब्दः	पृष्ठम्
कनकाह्वय	४०
कनिष्ठ	५७ ११७
कनिष्ठा	६१
कनीनिका	६२
कनीयस्	१०३ १३५
कन्था	१४१
कन्द	४८
कन्दर	३३
कन्दराल	३६ ३७
कन्दर्प	३
कन्दली	५०
कन्दु	८५
कन्दुक	६६
कन्धरा	६१
कन्यकाजात	५५
कन्या	५४
कपट	२२
कपर्द	४
कपर्दिन्	४
कपाट	३२
कपालभृत्	४
कपि	४९
कपिकच्छु	४१
कपित्थ	३५

	पृष्ठम्	श्लोकः
	१६	१६
	९	४
	३९	६३
	४४	१२०
	४२	९७
	१६	१६
	३६	२७
	३७	४३
	३९	६३
	५०	१४
लिका	३२	१५
त्रि	४५	१२९
	६१	९०
	५९	६२
	५९	६०
	६०	८०
	२५	४
	८२	११८
	४६	१३९
	६२	९७
	८६	४०
	१३७	२५०
	२६	२१
	२६	२४
	७०	४६
	१००	२४

शब्दः	पृष्ठम्	श्लोकः
कमल	२५	३
	२८	४०
	१३२	१९५
कमला	३	२८
कमलासन	२	१७
कमलोत्तर	९२	१०६
कमितृ	१००	२३
कम्प	२३	३८
कम्पन	१०४	७४
कम्प्र	१०४	७४
कम्बल	६४	११६
	१३२	१९५
कम्बलिवाह्यक	७६	५२
कम्बि	८६	३४
कम्बु	२६	२३
	१२६	१३३
कम्बुग्रीवा	६१	८८
कम्र	१००	२४
कर	१२	२३
	७४	२७
	१२९	१६४
करक	३९	६४
	११२	६
करका	१०	१२
करज	३८	४७
	४५	१२९
करंजक	३८	४७
करट	५१	२०
	११६	३४

शब्दः	पृष्ठम्	श्लो
करण	९३	
	११८	
करण्ड	१४१	
करतोया	२७	
करपत्र	९६	
करभ	६१	८
	९०	
करभूषण	६३	१०
करमर्दक	४०	६
करम्भ	८७	४
कररुह	६१	८
करवाल	८०	८
करवालिका	८०	९
करवीर	४०	७
करशाखा	६१	८
करशीकर	७५	३
करहाट	२८	४
करहाटक	३८	५
कराल	१३३	२०
करिगर्जित	८१	१०
करिणी	७५	३
करिन्	७५	३
करिपिप्पली	४२	९
करिशावक	७५	३
करीर	४०	७७
	१३०	१७४
करीष	८७	५९

शब्दः	पृष्ठम्	श्लोकः
हण	२१	१७
हणा	२१	१८
रेट्टु	५१	१९
रेणु	११८	५२
रोटि	५९	६९
कर्क	७६	४६
कर्कटक	२६	२१
कर्कटी	४८	१५५
कर्कन्धू	३७	३६
कर्करी	८६	२१
कर्करेट्टु	५१	१९
कर्कश	४७ १०५ १३४	१४६ ७६ २१८
कर्कारु	४८	१५५
कर्चूर	४७	१५४
कर्चूरक	४६	१३५
कर्ण	६२	९४
कर्णजलौकस्	५०	१३
कर्णधार	२५	१२
कर्णपूर	१३५	२२८
कर्णवेष्टन	६३	१०३
कर्णिका	६३ ११३	१०३ १५
कर्णिकार	३९	६०
कर्णीरथ	७६	५७
कर्णेजप	१०२	४७
कर्तरी	९६	३४
कर्दम	२५	९
कर्पट	६४	११५
कर्पर	५९	६८
कर्परीश	१३०	१७६
कर्परी	९२	१०१
कर्पूर	६५	१३०
कर्बुर	७ १७ ९१	६४ १७ ९४
कर्मकर	९४ ९९	१५ १९
कर्मकार	९९	१९
कर्मक्षम	९९	१८
कर्मठ	९९	१८
कर्मण्या	९६	३८
कर्मंदिन्	७०	४२
कर्मशील	९९	१८
कर्मशूर	९९	१८
कर्मसचिव	७२	४
कर्मार	४८	१६०
कर्मेन्द्रिय	१६	८
कर्ष	९१	८६
कर्षक	८३	६
कर्षफल	३९	२८
कर्षू	१३४	२२३
कल	१९	२
कलकल	१९	
कलङ्क	१० ११२	
कलत्र	१३०	
कलधौत	१२०	
कलम्ब	८० ८६	
कलभ	७५	
कलम	८५	
कलम्बी	४८	
कलरव	५०	
कलल	५७	
कलविंक	५१	
कलश	८६	
कलशि	४२	
कलहंस	५१	
कलह	८१	
कला	१० १३ १३२	
कलाद	९४	
कलानिधि	१०	
कलाप	१२५	
कलाय	८४	
कलि	८१ १३२	
कलिका	३५	

शब्दः	पृष्ठम्	श्लोकः
	४०	६७
	५१	१६
	३९	५८
क	३८	४८
	१०५	८५
	१४	२३
	२६	१४
	६०	७०
	११३	१४
	१४	२१
	१४	२२
	७०	४०
	७४	२४
	७६	४२
	६	५४
	१४	२२
	१४	२३
	१७	१७
	१२	२
	५८	५७
	१२८	१६०
	१८	१८
	१४	२५
	२५	६
	७८	६४
	८८	५४
	११	२५
	६६	५

शब्दः	पृष्ठम्	श्लोकः
कविका	७६	४९
कविय	१४३	३५
कवोष्ण	१२	३५
कव्य	६८	२४
कशा	९६	३१
कशार्ह	१०२	४४
कशिपु	१२५	१३०
कशेरु	१४१	१३
कशेरुका	५९	६९
कश्मल	८२	१०९
कश्य	७६	४७
	९७	४०
	१०२	४४
कष	९६	३२
कषाय	१६	९
	१२८	१५३
कष्ट	२४	४
	११६	३९
कस्तूरी	६५	१२९
कह्लार	२८	३६
कह्व	५१	२२
कांस्यताल	२०	४
काक	५१	२०
काकचिंचा	४२	९८
काकतिन्दुक	३७	३९
काकनासिका	४४	११८
काकपक्ष	६२	९६

शब्दः	पृष्ठम्	श्लोकः
काकपीलुक	३७	
काकमाची	४७	
काकमुद्रा	४४	
काकली	१९	
काकाङ्गी	४४	
काकिणी	१४१	
काकु	१८	
काकुद	६१	
काकेन्दु	३७	
काकोदुम्बरिका	३९	
काकोदर	२३	
काकोल	२४	
	५१	
काङ्क्षा	२२	
काङ्क्षी	४५	
काच	९२	
	९६	
	११५	
काचस्थाली	३८	
काचित	१०६	
काञ्चन	९१	
काञ्चनाह्वय	३९	
काञ्चनी	८६	
काञ्ची	६३	
काञ्जिक	८६	
काण्ड	११७	
काण्डपृष्ठ	७८	

शब्दानुक्रमणिका.

ब्दः	पृष्ठम्	श्लोकः
काण्डवत्	७८	६९
काण्डीरं	७८	६९
काण्डेक्षु	४३	१०४
कातर	१००	२६
कात्यायनी	५	३९
	५५	१७
कादम्ब	५१	२३
कादम्बरी	९७	४०
कादम्बिनी	९	८
काद्रवेय	२३	४
कानन	३४	१
कानीन	५५	२४
कान्त	१०२	५२
कान्तलक	४५	१२८
कान्ता	५२	३
कान्तार	३०	१७
	१३०	१७२
कान्तारक	४८	१६३
कान्तार्थिनी	५४	१०
कान्ति	१०	१७
	१०९	८
कान्दविक	८५	२८
कान्दिशीक	१०१	४२
कापथ	३०	१६
कापोत	५३	४३
	९३	१०९
कापोताञ्जन	९२	१००

शब्दः	पृष्ठम्	श्लोकः
काम	३	२६
	२२	२८
	८८	५७
	१२६	१३८
कामङ्गामिन्	७९	७६
कामन	१००	२४
कामपाल	३	२४
कामम्	१३९	१३
कामयितृ	१००	२४
कामिनी	५३	३
	१२४	११२
कामुक	१००	२३
कामुका	५४	९
कामुकी	५४	९
काम्पिल्य	४७	१४६
काम्बल	७७	५४
काम्बविक	९४	८
काम्बोज	७६	४५
काम्बोजी	४६	१३८
काम्यदान	१०८	३
काय	६०	७१
	७१	५१
कायस्था	३९	५९
कारण	१५	२८
कारणा	२४	३
कारणिक	९८	७
कारण्डव	५२	३४

शब्दः	पृष्ठम्
कारम्भा	३९
कारवी	४४
	४७
	८६
	८६
कारवेल्ल	४७
कारा	८३
कारिका	११३
कारीष	११२
कारु	९३
कारुणिक	९९
कारुण्य	२१
कारोत्तर	९७
कार्तस्वर	९१
कार्तान्तिक	७३
कार्तिक	१४
कार्तिकिक	१४
कार्तिकेय	५
कार्त्स्न्य	१३०
कार्पास	६३
	१४३
कार्पासी	४४
कार्म	९९
कार्मण	१०८
कार्मुक	७९
कार्श्य	३७
कार्षापण	१९

शब्दः	पृष्ठम्	श्लोकः
	६९	३१
	२२	३१
	८६	३३
	८६	३३
	२२	३१
	१८	१३
	१०३	५४
	४९	१६६
	७६	४२
	२२	२२
	९३	१०८
	४२	९१
	८०	९३
	६२	९५
	४०	७३
	४४	१२१
	१४२	१९
	४४	१२१
	४५	१२४
	१०३	५४
	९१	९१
	८	७२
	९	३
	४५	१२७
	३८	५५
	५७	४८

शब्दः	पृष्ठम्	श्लोकः
कुमार	५	४४
	२०	१२
कुमारक	३६	२५
कुमारी	४०	७३
	५४	८
कुमुद	९	३
	२८	३७
कुमुदप्राय	३०	९
कुमुदबान्धव	१०	१३
कुमुदिका	३७	४०
कुमुदिनी	२८	३९
कुमुद्वत्	३०	९
कुमुद्वती	२८	३८
कुम्बा	६८	१८
कुम्भ	३७	३४
	७५	३७
	१२६	१३४
कुम्भकार	९४	६
कुम्भसम्भव	१०	२०
कुम्भिका	२८	३८
कुम्भी	३७	४०
कुम्भीर	२६	२१
कुरङ्ग	५०	८
कुरङ्गक	९५	२४
कुरण्टक	४०	७४
	४०	७५
कुरबक	४०	७५

शब्दः	पृष्ठम्
कुरर	५१
कुरुबक	४०
कुरुविन्द	४८
कुरुबिस्त	९१
कुल	५३
	६६
कुलक	३७
	४८
	९३
कुलटा	५४
कुलत्थिका	९२
कुलपालिका	५४
कुलश्रेष्ठिन्	९३
कुलसम्भव	६६
कुलस्त्री	५४
कुलाय	५३
कुलाल	९४
कुलाली	९२
कुलिश	६
कुली	४२
कुलीन	६६
कुलीर	२६
कुल्माष	८४
	१४२
कुल्माषाभिषुत	८६
कुल्य	५९
कुल्या	२७

दः	पृष्ठम्	श्लोकः
वल	२७	३६
वलय	२८	३७
वाद	१०१	३७
विन्द	९४	६
वेणी	२६	१६
श	४९	१६६
	१३४	२१६
शल	१४	२६
	९८	४
	१३२	२०४
कुशी	९२	९९
कुशीलव	९४	१२
कुशेशय	२८	४०
कुष्ठ	४५	१२६
	५८	५४
	१४३	३४
कुसीद	८३	४
कुसीदिक	८३	५
कुसुम	३५	१७
कुसुमाञ्जन	९२	१०३
कुसुमेषु	३	२७
कुसुम्भ	९२	१०६
	१२६	१३६
कुसृति	२२	३०
कुस्तुम्बुरु	८६	३८
कुहना	७१	५३
कुहर	२३	१
कुहू	१३	९
शब्दः	**पृष्ठम्**	**श्लोकः**
कूकुद	९९	१४
कूट	३३	४
	५३	४२
	११६	३७
कूटयन्त्र	९५	२६
कूटशाल्मलि	३८	४७
कूटस्थ	१०४	७३
कूप	२७	२६
कूपक	२५	१०
	२५	१२
कूबर	७७	५७
कूर्च	६२	९२
कूर्चशीर्ष	४६	१४२
कूर्चिका	८७	४४
कूर्दन	२२	३३
कूर्पर	६०	८०
कूर्पासक	६४	११८
कूर्म	२६	२१
कूल	२५	७
कूष्माण्डक	४८	१५५
कृकण	५१	१९
कृकलास	५०	१२
कृकवाकु	५१	१७
कृकाटिका	६१	८८
कृच्छ्र	२४	४
	७१	५२
कृत	१२०	७७
शब्दः	**पृष्ठम्**	
कृतपुङ्ख	७८	
कृतमाल	३६	
कृतमुख	९८	
कृतलक्षण	९९	
कृतसापत्निका	५४	
कृतहस्त	७८	
कृतान्त	७	
	११९	
कृताभिषेका	५४	
कृतिन्	६६	
	९८	
कृत्त	१०७	
कृत्ति	७१	
कृत्तिवासस्	४	
कृत्या	१२८	
कृत्रिमधूपक	६५	
कृत्स्न	१०४	
कृपण	१०२	
कृपा	२१	
कृपाण	८०	
कृपाणी	९६	
कृपालु	९९	
कृपीटयोनि	६	
कृमि	५०	
कृमिकोशोत्थ	६३	
कृमिघ्न	४३	
कृमिज	६५	

	पृष्ठम्	श्लोकः
	१०३	६१
	६	५८
तस्	४	३६
तू	१४	१२
	८३	६
	८४	१३
	८३	२
	८३	६
	८३	८
	६६	६
	१३	१२
	१६	१४
	८६	३६
कफल	४०	६७
टा	४२	९६
ा	४१	८६
	४२	९८
हित	१६	१६
र्मन्	६	५८
ता	३८	५५
र	५०	१०
	४२	९६
ा	८४	१९
	५८	४९
	५२	३१
	५२	३०
	४९	१७०

शब्दः	पृष्ठम्	श्लोकः
केतन	८१ १२४	९९ ११४
केतु	११९	६०
केदर	१४२	२०
केदार	८४	११
केनिपातक	२५	१३
केयूर	६३	१०७
केलि	२२	३२
केवल	१३२	२०४
केश	६२	९५
केशपर्णी	४२	८९
केशपाशी	६२	९७
केशव	३ ५७	१८ ४५
केशवेश	६२	९७
केशाम्बुनाम	४५	१२२
केशिक	५७	४५
केशिन्	५७	४५
केशिनी	४५	१२६
केसर	२८ ३६ ३९ ३९	४३ २५ ६४ ६५
केसरिन्	४९	१
कैटभजित्	३	२२
कैडर्य	३७	४०
कैतव	२२ ९७	३० ४५

शब्दः	पृष्ठम्	श्लो
कैदारक	८४	
कैदारिक	८४	
कैदार्य	८४	
कैरव	२८	
कैलास	८	
कैवर्त	२६	
कैवर्तीमुस्तक	४५	१
कैवल्य	१६	
कैशिक	६२	
कैश्य	६२	
कोक	५० ५१	
कोकनद	२८	
कोकनदच्छवि	१६	
कोकिल	५१	
कोकिलाक्ष	४३	१
कोटर	३५	
कोटवी	५५	
कोटि	७९ ८० ११६	
कोटिवर्षा	४६	१३
कोटिश	८४	
कोट्टार	१४१	
कोठ	५८	
कोण	२० ८०	

शब्दः	पृष्ठम्	श्लोकः
कोदण्ड	७९	८३
कोद्रव	८४	१६
कोप	२२	२६
कोपना	५३	४
कोपिन्	१०१	३२
कोमल	१०५	७८
कोयष्टिक	५२	३५
कोरक	३५	१६
कोरङ्गी	४५	१२५
कोरदूष	८४	१६
कोल	२५	११
	३७	३६
	४९	२
कोलक	६५	१२९
	८६	३६
कोलदल	४५	१३०
कोलम्बक	२०	७
कोलवल्ली	४२	९७
कोला	४२	९७
कोलाहल	१९	२५
कोलि	३७	३६
कोविद	६६	५
कोविदार	३५	२२
कोश	५३	३७
कोशफल	६५	१३०
कोशातकी	११३	८
कोष	९१	९१

शब्दः	पृष्ठम्	श्लोकः
कोष्ठ	११७	४०
कोष्ण	१२	३५
कौक्कुटिक	११३	१७
कौक्षेयक	८०	८९
कौटतक्ष	९४	९
कौटिक	९४	१४
कौणप	७	५९
कौतुक	२२	३१
कौतूहल	२२	३१
कौद्रवीण	८३	८
कौन्ति	४४	१२०
कौन्तिक	७८	७०
कौपीन	१२१	१२२
कौमुदी	१०	१६
कौमोदकी	४	३०
कौलटिनेय	५६	२७
कौलटेय	५५	२६
	५६	२७
कौलटेर	५५	२६
कौलीन	१२४	११६
कौलेयक	९५	२१
कौशिक	३७	३४
	११३	१०
कौशेय	६३	१११
कौस्तुभ	४	३०
क्रकच	९६	३५
क्रकर	४०	७७
	५१	१९

शब्दः	पृष्ठम्
क्रतु	६७
क्रतुध्वंसिन्	४
क्रतुभुज्	२
क्रथन	८२
क्रन्दन	८१
	१२५
क्रन्दित	२२
क्रम	७०
क्रमुक	३७
	३७
	४९
क्रमेलक	९०
क्रयविक्रयिक	९०
क्रयिक	९०
क्रय्य	९०
क्रव्य	५९
क्रव्यात्	७
क्रव्याद	७
क्रायिक	९०
क्रिया	१२८
क्रियावत्	९९
क्रीडा	२२
	२२
क्रुञ्च्	५१
क्रुध्	२२
क्रुष्ट	२२

	पृष्ठम्	श्लोकः
	१०२ १०५ १३१	४७ ७६ १९२
	९०	८१
	९०	८१
	४९ ६०	२ ७७
	२२	२६
	१०१	३२
	३१	१८
	४९	५
ा	४२	९३
	४३	११०
	५१	२२
ण	५	४४
	१०९	१०
	१०९	१०
	१०७	१०५
	५९	६०
	१०७	९८
	१८ १०८	१९ ९८
	४३	१०९
का	४२	९४
	५७ १३३	२९ २१२
	१११	२९
	५९	६५

शब्दः	पृष्ठम्	श्लोकः
क्वण	१९ १०९	२४ ८
क्वणन	१९	२४
क्वथित	१०६	९५
क्वाण	१९	२४
क्षण	१३ २३ ११७	११ ३८ ४७
क्षणदा	१२	४
क्षणन	८२	११४
क्षणप्रभा	९	९
क्षतज	५९	६४
क्षतव्रत	७१	५४
क्षत्तृ	७७ ९३ ११९	५९ ३ ६३
क्षत्रिय	७२	१
क्षत्रिया	५४	१४
क्षत्रियी	५४	१५
क्षत्रियाणी	५४	१४
क्षन्तृ	१००	३१
क्षपा	१२	४
क्षपाकर	१०	१५
क्षम	१२७	१४३
क्षमा	१२७	१४३
क्षमितृ	१००	३१
क्षमिन्	१००	३१

शब्दः	पृष्ठम्
क्षय	१४ ५८ १०९ १२७
क्षव	५८ ८४
क्षवथु	५८
क्षान्त	१०६
क्षान्ति	२१
क्षार	९२
क्षारक	३५
क्षारमृत्तिका	२९
क्षारित	१०२
क्षिति	२९ १२०
क्षिपा	१०९
क्षिप्त	१०६
क्षिप्नु	१००
क्षिप्र	७ १०८
क्षिया	१०९
क्षीर	२६ ८७ १३०
क्षीरविकृति	८७
क्षीरविदारि	४३
क्षीरशुक्ला	४३
क्षीरावी	४३

ब्दः	पृष्ठम्	श्लोकः
क्षीरिका	३८	४५
क्षीरोद	२५	२
क्षीव	१००	२३
क्षुत्	५८	५२
क्षुत	५८	५२
क्षुताभिजनन	८४	१९
क्षुद्र	१०२	४८
	१३०	१७८
क्षुद्रघण्टिका	६३	११०
क्षुद्रशङ्ख	२६	२३
क्षुद्रा	४२	९४
	१३०	१७७
क्षुद्राण्डमत्स्यसंघात	२६	१९
क्षुप	३४	८
क्षुमा	८५	२०
क्षुर	४३	१०४
क्षुरक	३७	४०
क्षुरप्र	१४२	२०
क्षुरिन्	९४	१०
क्षुल्लक	९४	१६
	१०३	६१
	११३	१०
क्षेत्र	८४	११
	१३०	१८०
क्षेत्रज्ञ	१५	२९
	११६	३३

शब्दः	पृष्ठम्	श्लोकः
क्षेत्राजीव	८३	६
क्षेपण	१०९	११
क्षेपणी	२५	१३
क्षेपिष्ठ	१०८	१११
क्षेम	१४	२६
	४५	१२८
	१४३	३४
क्षोणि	२९	२
क्षोद	८१	९९
शोदिष्ठ	१०८	१११
क्षौद्र	९३	१०७
क्षौम	३२	१२
	६३	११३
क्ष्णुत	१०६	९१
क्ष्मा	२९	३
क्ष्माभृत्	३३	१
	७२	१
क्ष्वेड	२४	९
क्ष्वेडा	८१	१०७
	११७	४३
क्ष्वेडित	१४३	३४

ख

शब्दः	पृष्ठम्	श्लोकः
ख	८	१
	११४	१८
खग	५२	३२
	८०	८६
	११४	१९
खगेश्वर	४	३२
खजाका	८६	३४

शब्दः	पृष्ठम्
खञ्ज	५८
खञ्जन	५०
खञ्जरीट	५०
खट	१४१
खट्वा	६६
खड्ग	४९
	८०
खड्गिन्	४९
खण्ड	१०
	२८
खण्डपरशु	१०
खण्डविकार	८७
खदिर	३८
खदिरा	४६
खद्योत	५२
खनि	३३
खनित्र	८४
खपुर	४९
खर	१२
	९०
खरणस्	५७
खरणस	५७
खरपुष्पा	४६
खरमञ्जरी	४२
खरा	४०
खराश्वा	४४
खर्जू	५८

पृष्ठम्	श्लोकः
४९	१७०
९२	९६
४९	१७०
५७	४६
१०४	७०
१०२	४७
९९	१७
११२	४२
७६	४९
१३७	२५५
८४	१५
११२	४२
२७	२७
१०८	११०
९१	८८
८४	१०
८४	१०
२९	५
४५	१३०
७६	४९
५७	४७
५७	४७
१०३	५४
२७	२९
२२	३३
५८	४९
९८	९

शब्दः	पृष्ठम्	श्लोकः
ख्यातगर्हण	१०६	९३
ख्याति	१०९	९
ग		
गगन	८	१
गङ्गा	२७	३१
गङ्गाधर	४	३७
गज	७५	३४
गजता	७५	३६
गजबन्धनी	७६	४३
गजभक्ष्या	४५	१२३
गजानन	५	४१
गञ्जा	३१	८
गडक	२६	१७
गडु	१४१	१८
गडुल	५७	४८
गण	५३	४०
	११७	४६
गणक	७३	१४
गणदेवता	२	१०
गणनीय	१०३	६४
गणरात्र	१२	६
गणरूप	४१	८०
गणहासक	४५	१२८
गणाधिप	५	४१
गणिका	४०	७१
	५५	१९
गणिकारिका	३९	६६

शब्दः	पृष्ठम्
गणित	१०३
गणेय	१०३
गण्ड	६१ ७५
गण्डक	४९
गण्डकारी	४६
गण्डशैल	३३
गण्डाली	४८
गण्डीर	४८
गण्डूपद	२६
गण्डूपदी	२७
गण्डूषा	१४१
गतनासिक	५७
गद	५८
गद्य	१४३
गन्त्री	७६
गन्ध	१६
गन्धकुटी	४५
गन्धन	१२४
गन्धनाकुली	४४
गन्धफली	३९ ३९
गन्धमादन	३३
गन्धमूली	४७
गन्धरस	९२

शब्दः	पृष्ठम्	श्लोकः
गन्धर्व	२	११
	६	५६
	५०	११
	७६	४४
	१२६	१३३
गन्धर्वहस्तक	३८	५०
गन्धवह	७	६६
गन्धवहा	६१	८९
गन्धवाह	७	६६
गन्धसार	६५	१३१
गन्धाश्मन्	९२	१०२
गन्धिक	९२	१०२
गन्धिनी	४५	१२३
गन्धोत्तमा	९७	४०
गन्धोली	५२	२७
गभस्ति	१२	३३
गभीर	२६	१५
गम	८०	९५
गमन	८०	९५
गम्भारी	३७	३५
गम्भीर	२६	१५
गम्य	१०६	९२
गरण	१११	३७
गरल	२४	९
गरा	४०	६९
गरिष्ठ	१०८	११२
गरी	४०	६९

शब्दः	पृष्ठम्	श्लोकः
गरुड	४	३२
गरुडध्वज	३	१९
गरुडाग्रज	१२	३२
गरुत्	५२	३६
गरुत्मत्	४	३२
	५२	३४
	११८	५८
गर्गरी	९०	७४
गर्जित	९	८
	७५	३६
गर्त	२३	२
गर्दभ	९०	७७
गर्दभाण्ड	३७	४३
गर्द्धन	१००	२२
गर्भ	५७	३९
	१२६	१३५
गर्भक	६५	१३५
गर्भागार	३१	८
गर्भाशय	५७	३८
गर्भिणी	५५	२२
गर्भोपघातिनी	८९	६९
गर्मुत्	४८	१६५
गर्व	२१	२२
गर्वित	१२३	१०३
गर्हण	१८	१३
गर्ह्य	१०३	५४
गर्ह्यवादिन्	१०१	३७

शब्दः	पृष्ठम्
गल	६१
गलकम्बल	८९
गलन्तिका	८६
गलित	१०७
गलोद्देश	७६
गल्या	११२
गवय	५०
गवल	९२
गवाक्ष	३२
गवाक्षी	४८
गवीन	८८
गवीश्वरम्	८८
गवेधु	८५
गवेधुका	८५
गवेषणा	६९
गवेषित	१०७
गव्य	८७
गव्या	८८
गव्यूति	३१
गहन	३४
	१०५
गह्वर	३
	१३
गाङ्गेय	९
	१२
गाङ्गेरुकी	४
गाढ	

	पृष्ठम्	श्लोकः
	५५	२२
	७९	८४
	७९	८४
	६०	७०
	७५	४०
पर्नी	६५	१३३
	१९	२६
	१९	१
	३८	४९
	९१	९२
	५५	२२
	६८	१९
	३६	३३
	१७	१
	३३	१
	१०९	११
	४३	१०४
	५०	१२
	९२	१०४
	५	४१
ल	९२	१००
का	३९	६६
	४	३४
	४	३४
	१०८	११०
	१९	२६
	१०८	११०

शब्दः	पृष्ठम्	श्लोकः
गीर्णि	१०९	११
गीर्वाण	२	९
गीष्पति	११	२४
गुग्गुल	३७	३४
गुच्छ	६३ ८५	१०५ २१
गुच्छक	३५	१६
गुच्छार्ध	६३	१०५
गुञ्जा	४२	९८
गुड	११७	४२
गुडपुष्प	३६	२७
गुडफल	३६	२८
गुडा	४३	१०५
गुडूची	४१	८२
गुण	१५ ७९ ८५ ९५ ११७	२९ ८५ २८ २७ ४७
गुणवृक्षक	२५	१२
गुणित	१०६	८८
गुण्ठित	१०६	८९
गुद	६०	७३
गुन्द्र	४८	१६२
गुन्द्रा	३८ ४८	५५ १६०
गुप्त	१०६ १०७	८९ १०६

शब्दः	पृष्ठम्	श्लो
गुप्तवाद	१२९	
गुप्ति	१२०	
गुरण	१०९	
गुरु	११ ६७ १२९	
गुर्विणी	५५	
गुल्फ	६०	
गुल्म	३४ ५९ ७९ १२७	
गुल्मिनी	३४	
गुवाक	४९	
गुह	५	
गुहा	३३ ४२	
गुह्य	१२८	
गुह्यक	२	
गुह्यकेश्वर	८	
गूढ	१०६	
गूढपात्	२३	
गूढपुरुष	७३	
गूथ	५९	
गून	१०६	
गृञ्जन	४७	
गृध्नु	१००	
गृध्र	५१	

शब्दः	पृष्ठम्	श्लोकः
प्रसी	१४१	१०
ष्टि	४७	१५१
ह	३१	४
	३१	५
	१३६	२३८
गृहगोधिका	५०	१२
गृहपति	७३	१५
गृहयालु	१००	२७
गृहस्थूण	१४३	३०
गृहागत	६९	३४
गृहाराम	३४	१
गृहावग्रहणी	३२	१३
गृहिन्	६६	३
गृह्यक	५३	४३
	९९	१६
गेन्दुक	६६	१३८
गेह	३१	४
गैरिक	३३	८
	११३	१२
गैरेय	९२	१०४
गो(गौ)	८८	६०
	८९	६६
	११५	२५
गोकण्टक	४२	९९
गोकर्ण	५०	१०
	६१	८३
गोकर्णी	४१	८४
गोकुल	८८	५८

शब्दः	पृष्ठम्	श्लोकः
गोक्षुरक	४२	९९
गोचर	१६	८
गोजिह्वा	४४	११६
गोडुम्बा	४८	१५९
गोण्ड	१४१	१८
गोत्र	३३	१
	६६	१
	१३०	१८१
गोत्रभिद्	५	४६
गोत्रा	२९	३
	८८	६०
गोदारण	८४	१४
गोदुह्	८८	५७
गोधन	८८	५८
गोधा	७९	८४
गोधापदी	४४	११९
गोधि	६२	९२
गोधिका	२६	२२
गोधूम	८४	१८
गोनर्द	४५	१३२
गोनस	२३	४
गोप	७२	७
	८८	५७
	१२५	१३०
गोपति	८८	६२
गोपरस	९२	१०४
गोपानसी	३२	१५

शब्दः	पृष्ठम्
गोपायित	१०७
गोपाल	८८
गोपी	४४
गोपुर	३२
	४५
	१३०
गोप्यक	९५
गोमत्	८८
गोमय	८७
गोमायु	४९
गोमिन्	८८
गोरस	४८
गोर्द	५९
गोळ	१४२
गोलक	५६
गोला	९३
गोलीढ	३७
गोलोमी	४३
	४८
	९३
गोवन्दनी	३८
गोविड्	८७
गोविन्द	३
	१२२
गोशीर्ष	६५
गोष्ठ	३०
गोष्ठपति	१२५

पृष्ठम्	श्लोकः
१० ४७ १३०	१३ १४६ १८३
५२	३१
२७	३४
१०	१३
४५	१२५
४	३३
६५	१३०
८०	८९
१०	१६
७ ९२ १०२	६९ ९९ ४६
९ ४२	९ ९६
६१	८४
[illegible]	१०
३५	२२
१४३	३५
१४१	१०
७९ ७९	७८ ८१
५०	९
३९	६३
३१ ५३	३ ४०

शब्दः	पृष्ठम्	श्लोकः
चर	७२ १०४	१३ ७४
चरक	१४३	३३
चरण	६०	७१
चरणायुध	५१	१७
चरम	१०५	८१
चरमक्ष्माभृत्	३३	२
चराचर	१०४	७४
चरिष्णु	१०४	७४
चरु	६८	२२
चर्चरी	१४१	१०
चर्चा	१५ ६४	२ १२२
चर्मन्	७१ ८०	४७ ९०
चर्मकषा	४६	१४३
चर्मकार	९४	७
चर्मप्रभेदिका	९६	३५
चर्मप्रसेत्रिका	९६	३३
चर्मिन्	३८ ७८	४६ ७१
चर्या	६९	३६
चर्वित	१०८	११०
चल	१०४	७४
चलदल	३५	२०
चलन	१०४	७४
चलाचल	१०४	७४

शब्दः	पृष्ठम्	
चलित	८० १०६	
चविका	४२	
चव्य	४२	
चषक	९७	
चषाल	६८	
चाक्रिक	८१	
चाङ्केरी	४६	१
चाटकैर	५१	
चाण्डाल	९५	
चाण्डालिका	९६	
चातक	५१	
चातुर्वण्य	६६	
चाप	७९	८
चामर	७५	३
चामीकर	९१	९
चाम्पेय	३९ ६९	
चार	७३ १०९	१ १
चारटी	४७	१४
चारण	९४	१
चारु	१०२	५
चार्चिक्य	६४	१२
चालनी	८५	२
चाष	५१	१
चिकित्सक	५८	५

ब्दः	पृष्ठम्	श्लोकः
कित्सा	५८	५०
कुर	६२	९५
	१०२	४६
क्कण	८७	४६
क्कस	१४३	३५
ञ्चा	३७	४३
त्	१५	१
	१३८	३
ता	८२	११७
ति	८२	११७
चित्त	१५	३१
चित्तविभ्रम	२२	२६
चित्तसमुन्नति	२१	२२
चित्ताभोग	१५	२
चित्या	८२	११७
चित्र	१७	१७
	२१	१९
	१३०	१७९
चित्रक	३८	५१
	४१	८०
	६४	१२३
चित्रकर	९४	७
चित्रकृत्	३६	२७
चित्रतण्डुला	४३	१०६
चित्रपर्णी	४२	९२
चित्रभानु	६	६०
	११	३०
	१२३	१०५

शब्दः	पृष्ठम्	श्लोकः
चित्रशिखण्डज	११	२४
चित्रशिखण्डिन्	११	२७
चित्रा	४१	८७
	४८	१५६
चिन्ता	२२	२९
चिपिटक	८७	४७
चिबुक	६१	९०
चिरक्रिय	९९	१७
चिरन्तन	१०५	७७
चिरप्रसूता	८९	७१
चिररात्राय	१३८	१
चिरस्य	१३८	१
चिराय	१३८	१
चिरिबिल्व	३८	४७
चिरिण्टी	५४	९
चिलिचिम	२६	१८
चिल्ल	५१	२१
	५९	६०
चिह्न	१०	१७
चीन	५०	९
चीर	१४३	३१
चीरि	५२	२८
चीवर	१४३	३१
चुक्र	४६	१४१
	८६	३५
	१४२	२०
चुक्रिका	४६	१४०

शब्दः	पृष्ठम्
चुल्ल	५९
चुल्लि	८५
चूचुक	६०
चूडा	५२
	६२
चूडामणि	६२
चूडाला	४८
चूत	३६
चूर्ण	६५
	८१
चूर्णकुन्तल	६२
चूर्णि	१४१
चूलिका	७५
चेटक	९५
चेत्	१३९
चेतकी	३९
चेतन	१५
चेतना	१५
चेतस्	१५
चैत्य	३१
चैत्र	१३
चैत्ररथ	८
चैत्रिक	१३
चैल	६४
	१३२
चोच	४६
	१४३

	पृष्ठम्	श्लोकः
ो	४५	१२६
	६४	११८
	९५	२४
	९५	२५
	९५	२५
	१०७	१०४
	छ.	
	९०	७६
त्री	४६	१३७
	७५	३२
	४३ ४९ ८६	१०५ १६७ ३७
	४४	११५
	३५ ५२	१४ ३६
	३५	१४
	३२	१४
	२२	३०
	११८ १२१	२० ८८
	६८ १३५	२२ २३३
	७४ १०७	२२ ९८
	८२	१०८
	१८ १२	१७ ३४

शब्दः	पृष्ठम्	श्लोकः
छाग	९०	७६
छागी	९०	७६
छात	५७ १०७	४४ १०३
छात्र	६७	११
छादित	१०७	९८
छान्दस	६६	६
छाया	१२८	१५८
छित	१०७	१०३
छिद्र	२३	२
छिद्रित	१०७	९९
छिन्न	१०७	१०३
छिन्नरुहा	४१	८२
छुरिका	८०	९२
छेक	५३	४३
छेदन	१०९	७
	ज	
जगत्	२९ १२०	६ ८०
जगती	२९ १२०	६ ७१
जगत्प्राण	६	६६
जगर	७८	६४
जगल	९७	४२
जग्ध	१०८	१११
जग्धि	८८	५५
जघन	६०	७४

शब्दः	पृष्ठम्	श्ल
जघनेफला	३९	
जघन्य	१०५ १२८	 १
जघन्यज	५७ ९३	
जङ्गम	१०४	
जङ्गमेतर	१०४	
जङ्घा	६०	
जङ्घाकरिक	७८	
जङ्घाल	७८	
जटा	३४ ६२ ११६	
जटाजूट	४	३
जटामांसी	४६	१३
जटिन्	३६	३
जटिला	४६	१३
जठर	६० १०५ १३९	७ ७ ११
जड	१० १०१	१ ३
जडुल	५८	४
जतु	६५	१२
जतुक	८६	४
जतुका	५१	२
जतुकृत्	४७	१५
जतूका	४७	१६

	पृष्ठम्	श्लोकः
	६०	७८
क	५६	२८
ङ्गम	९५	१९
ता	११२	४३
न	१५ ६६	३० १
नी	५६	२९
पद	३०	८
नयित्री	५६	२९
श्रुति	१७	७
नार्दन	३	१९
नाश्रय	३२	९
नि	१५	३०
नी	४७ ५४	१५३ ९
नुस्	१५	३०
न्तु	१५	३०
न्तुफल	३५	२२
न्मन्	१५	३०
न्मिन्	१५	३०
न्य	७२ ८१ १२८	५८ १०३ १५९
न्यु	१५	३०
नप	७१	४७
नपापुष्प	४०	७६
जम्पती	५७	३८

शब्दः	पृष्ठम्	श्लोकः
जम्बाल	२५	९
जम्बीर	४१	७९
जम्बु	३५	१९
जम्बुक	४९ ११२	५ ३
जम्बू	३५	१९
जम्भ	३६	२४
जम्भभेदिन्	५	४७
जम्भल	३६	२४
जम्भीर	३६	२४
जय	३९ ८२ १०९	६६ ११० १२
जयन	१०९	१२
जयन्त	६	५०
जयन्ती	३९	६५
जया	३९	६५
जय्य	७८	७४
जरण	८६	३६
जरत्	५७	४२
जरद्गव	८८	६१
जरा	५७	४१
जरायु	५७	३८
जरायुज	१०२	५०
जल	२५ १४२	३ २३
जलजन्तु	२६	२०

शब्दः	पृष्ठम्
जलधर	९
जलनिधि	२४
जलनिर्गम	२५
जलनीली	२८
जलपुष्प	१४२
जलप्राय	३०
जलमुक्	९
जलव्याल	२३
जलशुक्ति	२६
जलाधार	२७
जलाशय	२७ ४८
जलोच्छ्वास	२५
जलौकस्	२६
जलौका	२६
जल्पाक	१०१
जल्पित	१०७
जव	७ ७८
जवन	७६ ७८ १११
जवनिका	६४
जह्नुतनया	२७
जागरा	११०
जागरित	१०१
जागरूक	१०१

	पृष्ठम्	श्लोकः
	११०	१९
क	२४	११
	७८	७३
	१५ १२१	३१ ८५
	९१	९५
सू	६	५७
त्या	५५	१६
	१५ ४० ११९	३१ ७२ ६८
	३५	१९
शि	६५	१३२
ल	६५	१३२
	१३८	४
	८८	६१
	६०	७२
	९४	११
	५६	३२
	१२७	१४२
	३५	१९
र	९१	९५
	६५	१२५
	५४	६
त्र	९४	१२
	५७	३८

शब्दः	पृष्ठम्	श्लोकः
जायु	५८	५०
जार	५६	३५
जाल	२१ १३२	१६ २०१
जालक	३५	१६
जालिक	९४	१४
जाली	४४	११८
जाल्म	९४ ९९	१६ १७
जिघत्सु	९९	२०
जिङ्गी	४२	९०
जित्वर	७९	७७
जिन	२	१३
जिष्णु	५ ७९	४६ ७७
जिह्म	१०४ १२७	७१ १४१
जिह्मग	२४	८
जिह्वा	६१	९१
जीन	५७	४२
जीमूत	९ ४० ११८	७ ६९ ५८
जीरक	८६	३६
जीर्ण	५७	४२
जीर्णवस्त्रा	६४	११५
जीर्णि	१०९	९

शब्दः	पृष्ठम्
जीव	११ ८३
जीवक	३७ ४६
जीवंजीव	५२
जीवन	२५ ८३
जीवनी	४६
जीवनीया	४६
जीवनौषध	८३
जीवन्तिका	४१ ४१
जीवन्ती	४६
जीवा	४६
जीवातु	८३
जीवान्तक	९४
जीविका	८३
जीवितकाल	८३
जुगुप्सा	१८
जुङ्ग	४६
जुहू	६८
जूति	१११
जूर्ति	१११
जृम्भ	२२
जृम्भण	२२
जेतृ	७८ ७९

ः: पृष्ठम् श्लोकः
न ८८ ५६
७८ ७४
७८ ७४
शातृक १० १४
९८ ६
११३ ११
ङ्गक ६५ १२६
त्स्नी ४४ ११८
षम् १३७ २५१
६६ ५
पित १०७ ९८
म १०७ ९८
ति १५ १
तसिद्धान्त ७३ १५
ाति ५६ ३४
ातृ १०० ३०
ातेय ५६ ३५
ान १६ ६
ानिन् ७३ १४
ज्या २९ २
७९ ८५
ज्याघातवारण ७९ ८४
ज्यानि १०९ ९
ज्यायस् ५७ ४३
१३५ २३५
ज्येष्ठ १३ १६
११७ ४१

शब्दः पृष्ठम् श्लोकः
ज्योतिरिङ्गण ५२ २८
ज्योतिषिक ७३ १४
ज्योतिष्मती ४७ १५०
ज्योतिस् १३५ २३०
ज्योत्स्ना १० १६
ज्योत्स्नी ४४ ११८
ज्यौत्स्नी १२ ५
ज्वर ५८ ५६
१११ ३९
ज्वलन ६ ५७
ज्वाल ७ ६१

झ

झटामला ४५ १२७
झटिति १३८ २
झर ३३ ५
झर्झर २० ८
झल्लरी १४१ १०
झष २६ १७
झषा ४४ ११७
झाटल ३७ ३९
झाटलि १४३ ३८
झावुक ३७ ४०
झिण्टी ४० ७४
४० ७५
झिल्लिका ५२ २८
झीरुका ५२ २८

शब्दः पृष्ठम्

ट

टङ्क ९६
टिट्टिभ ५२
टीका १४०
टुण्टुक ३९

ड

डमर १०९
डमरु २०
डयन ७६
डहु ३९
डिण्डिम २०
डिण्डीर ९२
डिम्ब १०९
डिम्भ ५३
१२६
डिम्भा ५७
डुण्डुभ २३
डुलि २७

ढ

ढक्का २०

त

तक्र ८८
तक्षक ११२
तक्षन् ९४
तट २५
तटिनी २७
तडाग २७

	पृष्ठम्	श्लोकः
	९	९
र्	९	७
	४३	१०६
यक	४६	१३६
	२०	४
	१०५	८६
	१३८	३
	७४	२९
	२०	९
	९८	९
	१३८	९
	२	१३
	१९	२२
	१३८	३
	१४०	२२
	७४	२९
	१४०	२२
	५६	२७
	६०	७१
	१०३	६१
	१०४	६६
	१२४	११३
	७८	६४
	६०	७१
	१०७	९९
द्	६	५७
	५२	३६
	६२	९९

शब्दः	पृष्ठम्	श्लोकः
तन्तु	९६	२८
तन्तुभ	८४	१७
तन्तुवाय	५०	१३
	९४	६
तन्त्र	१३१	१८५
तन्त्रक	६३	११२
तान्त्रिका	४१	८२
तन्द्री	२३	३७
	१३०	१७६
तप	१४	१९
तपःक्लेशसह	७०	४३
तपन	११	३१
	२४	१
तपनीय	९१	९४
तपस्	१३	१५
	१३५	२३२
तपस्य	१३	१५
तपस्विन्	७०	४२
तपस्विनी	४६	१३४
तम	११	२६
तमस्	१५	२९
	२३	३
	१३५	२३२
तमस्विनी	१२	४
तमाल	४०	६८
	१४३	३३
तमालपत्र	६४	१२३
तमिस्र	२३	३

शब्दः	पृष्ठम्	श्लो
तमिस्रा	१२	
तमी	१२	
तमोनुद्	१२१	
तमोपह	१३६	२
तरक्षु	४९	
तरङ्ग	२५	
तरङ्गिणी	२७	
तरणि	११	
	२५	
	४०	
तरपण्य	२५	
तरल	६२	१०
	१०४	
तरला	८७	५
तरस्	७	६
	८१	१०
तरस	५९	६
तरस्विन्	७८	७
	१२५	१२
तरि	२५	१
तरु	३४	
तरुण	५७	४
तरुणी	५४	
तर्क	१५	
तर्कविद्या	१७	
तर्कारि	३९	६
तर्जनी	६१	८

ब्दः	पृष्ठम्	श्लोकः
र्णक	८८	६१
र्दू	८६	३४
र्पण	६७	१४
	८८	५६
	१०८	४
र्मन्	६८	१९
र्ष	२२	२८
	८८	५५
ल	७९	८४
	१३२	२०२
लिन	१२५	१२७
ल्प	१२५	१३१
ळज	१४	२७
ष्ट	१०७	९९
स्कर	९५	२४
ाण्डव	२०	१०
	१४३	३४
तात	५६	२८
तान्त्रिक	७३	१५
तापस	७०	४२
तापसतरु	३८	४६
तापिच्छ	४०	६८
तामरस	२८	४०
तामलकी	४५	१२७
ताम्बूलवल्ली	४४	१२०
ताम्बूली	४४	१२०
ताम्रक	९२	९७

शब्दः	पृष्ठम्	श्लोकः
ताम्रकर्णी	९	५
ताम्रकुट्टक	९४	८
ताम्रचूड	५१	१७
तार	१९	२
	१२९	१६६
तारकजित्	५	४३
तारका	१०	२१
	६२	९२
तारा	१०	२१
तारुण्य	५७	४०
तार्क्ष्य	४	३२
	१२७	१४६
तार्क्ष्यशैल	९२	१०२
ताल	२०	९
	४९	१६८
	६१	८३
	९२	१०३
तालपत्र	६३	१०३
तालपर्णी	४५	१२३
तालमूलिका	४४	११९
तालवृन्तक	६६	१४०
तालाङ्क	३	२५
ताली	४५	१२७
	४९	१७०
तालु	६१	९१
तावत्	१३७	२४७
तिक्त	१६	९
तिक्तक	४८	१५५

शब्दः	पृष्ठम्
तिक्तशाक	३६
तिग्म	१२
तिङ्सुबन्तचय	१७
तितउ	८५
तितिक्षा	२१
तितिक्षु	१००
तित्तिरि	५२
तिथि	१२
तिनिश	३६
तिन्तिडी	३७
तिन्तिडीक	८६
तिन्दुक	३७
तिन्दुकी	१४०
तिमि	२६
तिमिङ्गिल	२६
तिमित	१०७
तिमिर	२३
तिरस्	१३८
	१३८
तिरस्करिणी	६४
तिरस्क्रिया	२१
तिरीट	३६
	१४३
तिरोधान	१०
तिरोहित	८२
तिर्यच्	१०१

	पृष्ठम्	श्लोकः
	३७ ५८ ५९ ६४ ८७	४० ४९ ६५ १२३ ४३
	५८	४९
	६५	१३२
	८४	१९
	८४	१९
	२३	५
	८३	७
	३६	३३
	१० १२७	२२ १४७
	३९	५७
	१२ ९२ ११८	३५ ९८ ५३
	३६	३१
	२५	७
	७१ १२१	५१ ८६
	८	७१
	२४	३
	१३६ १३८ १३९	२४२ ५ १५

शब्दः	पृष्ठम्	श्लोकः
तुङ्ग	३६ १०४	२५ ७०
तुङ्गी	४६	१३९
तुच्छ	१०३	५६
तुण्ड	६१	८९
तुण्डिकेरी	४४ ४६	११६ १३९
तुत्था	४२ ४५	९५ १२५
तुत्थाञ्जन	९२	१०१
तुन्द	६०	७७
तुन्दपरिमृज	९५	१८
तुन्दिन्	५७	४४
तुन्दिभ	५७ ५९	४४ ६१
तुन्दिल	५७ ५९	४४ ६१
तुन्न	४५	१२७
तुन्नवाय	९४	६
तुब(व)रिका	४५	१३१
तुमुल	८१	१०६
तुम्बी	४८	१५६
तुरग	७६	४३
तुरङ्ग	७६	४३
तुरङ्गम	७६	४३
तुरङ्गवदन	८	७५
तुरासाह्	५	४८

शब्दः	पृष्ठम्	श्लो
तुरुष्क	६५	१
तुला	९१	८
तुलाकोटि	६३	१
तुलामान	९१	८
तुल्य	९६	३
तुल्यपान	८८	
तुवर	१६	
तुष	३९ ८५	५ २
तुषार	१० १०	९ १
तुषित	२	१
तुहिन	१०	१
तूण	८०	८
तूणी	८०	८
तूणीर	८०	८
तूद	३७	४
तूर्ण	७	६
तूल	३७ ९२	४ १०
तूलिका	९६	३
तूबर	१२९	१६
तूष्णींशील	१०१	३
तूष्णीक	१०१	३
तूष्णीकाम्	१३८	
तूष्णीम्	१३८	
तृण	४९	१६

ब्दः	पृष्ठम्	श्लोकः
तृणद्रुम	४९	१७०
तृणधान्य	८५	२५
तृणध्वज	४८	१६०
तृणराज	४९	१६८
तृणशून्य	४०	६९
तृण्या	४९	१६८
तृतीयाकृत	८४	९
तृतीयाप्रकृति	५७	३९
तृप्त	१०७	१०३
तृप्ति	८८	५६
तृष्	२२	२७
	८८	५५
तृष्णक	१००	२२
तृष्णा	११८	५१
तेज	७४	२०
तेजन	४८	१६१
तेजनक	४८	१६२
तेजनी	४१	८३
तेजस्	५९	६२
	१३५	२३४
तेजित	१०६	९१
तेम	१११	२९
तेमन	८७	४४
तैजसावर्तनी	९६	३३
तैत्तिर	५३	४३
तैलपर्णिक	६५	१३१
तैलपायिका	५१	२६

शब्दः	पृष्ठम्	श्लोकः
तैलंपाता	१४०	६
तैलीनवत्	८३	७
तैष	१३	१५
तोक	५६	२८
तोकक	५१	१७
तोक्म	८४	१६
तोटक	१४३	३०
तोत्र	७५	४१
	८४	१२
तोदन	८४	१२
तोमर	८०	९३
तोय	२५	४
तोयपिप्पली	४४	१११
तोरण	३२	१६
तौर्य	२०	१०
त्यक्त	१०७	१०७
त्याग	६९	२९
त्रपा	२१	२३
त्रपु	९२	१०५
त्रयी	१७	३
त्रस	१०४	७४
त्रसर	११०	२४
त्रस्त	१००	२६
त्राण	१०७	१०६
	१०९	८
त्रात	१०७	१०६
त्रायन्ती	४७	१५०

शब्दः	पृष्ठम्
त्रायमाणा	४७
त्रास	२१
त्रिक	२०
	६०
त्रिककुद	३३
त्रिकटु	९३
त्रिका	२७
त्रिकूट	३३
त्रिखट्व	१४४
त्रिखट्वी	१४४
त्रिगुणाकृत	८४
त्रितक्ष	१४४
त्रितक्षी	१४४
त्रिदश	१
त्रिदशालय	१
त्रिदिव	१
त्रिदिवेश	१
त्रिपथगा	२७
त्रिपुटा	४३
	४५
त्रिपुरान्तक	४
त्रिफला	९३
त्रिभण्डी	४३
त्रियामा	१२
त्रिलोचन	४
त्रिवर्ग	७२
	७३

	पृष्ठम्	श्लोकः
	३	२०
	१	६
	४३	१०८
	४३	१०८
	१२	३
	८४	९
	२७	३१
	८४	९
	८९	६८
	४५ १०३ ११६	१२६ ६२ ३७
	६८ १११	२० ६९
	५२	३६
	४	३६
ख	८	७२
	९३	१११
	१०५	८२
	९३	१०९
	४६	१३४
	४८	१६०
	३५ ५९	१२ ६२
	४६	१३४
	४८	१६०
	११०	२६

शब्दः	पृष्ठम्	श्लोकः
त्वरित	७ ७८	६९ ७३
त्वरितोदित	१८	२०
त्वष्ट	१००	९९
त्वष्टृ	९४ ११६	९ ३५
त्विट्(ष्)	१२ १३५	३४ २२५
त्विषाम्पति	११	३०
त्सरु	८०	९०

द

शब्दः	पृष्ठम्	श्लोकः
दंश	५२	२७
दंशन	७८	६४
दंशित	७८	६५
दंशी	५२	२७
दंष्ट्रिन्	४९	२
दक्ष	९५	१९
दक्षिण	९८	८
दक्षिणस्थ	७७	६०
दक्षिणा	८	१
दक्षिणाग्नि	६८	१९
दक्षिणारु	९५	२४
दक्षिणार्ह	९८	५
दक्षिणीय	९८	५
दक्षिणेर्मन्	९५	२४
दाक्षिण्य	९८	५
दग्ध	१०७	९९

शब्दः	पृष्ठम्	श्लो
दग्धिका	८७	
दण्ड	१२ ७४ ७४ ११७	
दण्डधर	७	
दण्डनीति	१७	
दण्डविष्कम्भ	९०	
दण्डाहत	८८	
दद्रुघ्न	४७	१४
दद्रुण	५८	
दद्रुरोगिन्	५८	५
दधित्थ	३५	२
दधिफल	३५	२
दधिसक्तु	८७	४
दनुज	२	१
दन्त	६१	९
दन्तधावन	३८	४
दन्तभाग	७५	४
दन्तशठ	३५ ३६	२ २
दन्तशठा	४६	१४
दन्तावल	७५	३४
दन्तिका	४७	१४
दन्तिन्	७५	३४
दन्दशूक	२३	८
दभ्र	१०३	६

दः	पृष्ठम्	श्लोकः
त	७४ १०८	२१ ३
मथ	१०८	३
मित	१०६	९७
मुना	६	६०
म्पती	५७	३८
म्भ	२२	३०
म्भोलि	६	५१
म्य	८८	६२
या	२१	१८
यालु	९९	१५
यित	१०२	५३
र	२१ १३१	२१ १८५
रत्	१४१	९
दरिद्र	१०२	४९
दरी	३३	६
दर्दुर	२६	२४
दर्पक	३	२६
दर्पण	६६	१४०
दर्भ	४९	१६६
दर्वि	८६	३४
दर्वीकर	२३	८
दर्श	१३ ७१	८ ४८
दर्शक	७२	६
दर्शन	१११	३१

शब्दः	पृष्ठम्	श्लोकः
दल	३५	१४
दव	१३३	२०६
दविष्ठ	१०४	६९
दवीयस्	१०४	६९
दशन	६१	९१
दशनवासस्	६१	९०
दशबल	२	१४
दशमिन्	५७	४३
दशमीस्थ	१२१	८७
दशा	६४ १३४	११४ २१७
दशानीकिनी	७९	८१
दस्यु	७३ ९५	११ २४
दस्र	६	५५
दहन	६	५९
दाक्षायणी	५ १०	४१ २१
दाक्षाय्य	५१	२१
दाडिम	३९	६४
दाडिमपुष्पक	३८	४९
दाण्डपाता	१४०	६
दात	१०७	१०३
दात्यूह	५१	२१
दात्र	८४	१३
दान	६९ ७४ ७५	२९ २० ३७

शब्दः	पृष्ठम्
दानव	२
दानवारि	२
दानशौण्ड	९८
दान्त	७० १०६
दान्ति	१०८
दापित	१०१
दाम	८९
दामनी	८९
दामोदर	३
दाम्भिक	११३
दायाद	१२१
दारद	२४
दारा	५४
दारु	३५ ३८
दारुण	२१
दारुहरिद्रा	४३
दारुहस्तक	८६
दार्वाघाट	५१
दार्विका	४४
दार्वी	४३
दाव	१३३
दाविक	२८
दाश	२६
दाशपुर	४५
दास	९५

	पृष्ठम्	श्लोकः
	४०	७४
त	१४२	२७
	९५	१७
	९५	१७
	१०१	३९
	९	४
	८० १०६	३८ ९०
	१०७	१०३
	२	१२
	५५	२३
	५५	२३
	१२	२
	१२	३
	१ ८	६ १
	१२	२
	५	४६
	१३८	६
	११	२८
तें	९४ ९५	१० १९
	१	८
	१ १३५	७ २२७
न	१२६	१२३
दुक	१०२	५०

शब्दः	पृष्ठम्	श्लोकः
दिश्	८	१
दिश्य	८	२
दिष्ट	१२ १५ ११६	१ २८ ३५
दिष्टान्त	८२	११६
दिष्टया	१३८	१०
दीक्षान्त	६९	२७
दीक्षित	६७	८
दीदिवि	८७	४८
दीधिति	१२	३३
दीन	१०२	४९
दीप	६६	१३८
दीपक	११३	११
दीप्ति	१२	३४
दीप्य	४४	१११
दीर्घ	१०४	६९
दीर्घकोशिका	२७	२५
दीर्घदर्शिन्	६६	६
दीर्घपृष्ठ	२३	८
दीर्घवृन्त	३९	५७
दीर्घसूत्र	९९	१७
दीर्घिका	२७	२८
दुःख	२४ १४२	३ २३
दुःप्रधर्षिणी	४४	११४
दुःषमम्	१३९	१४

शब्दः	पृष्ठम्	श्लो
दुःस्पर्श	४२	
दुःस्पर्शा	४२	
दुकूल	६३	१
दुग्ध	८७	
दुग्धिका	४३	१
दुन्द्रुम	४७	१४
दुन्दुभि	२० १२६	 १३
दुरध्व	३०	१
दुरालभा	४२	९
दुरित	१४	२
दुरोदर	१२९	१७
दुर्ग	७३	१
दुर्गत	१०२	४
दुर्गति	२४	
दुर्गन्ध	१६	१
दुर्गसंचर	११०	२
दुर्गा	५	४
दुर्जन	१	
दुर्दिन	१०	१
दुर्नामक	५८	५
दुर्नामन्	२७	२
दुर्बल	५७	४
दुर्मनस्	९८	८
दुर्मुख	१०१	३
दुर्व्रण	९२	९

ब्दः	पृष्ठम्	श्लोकः
विधि	१०२	४९
हृद्	७३	१०
च्यवन	५	४८
कृत	१४	२३
षु	१३९	१९
पत्र	४५	१२८
हितृ	५६	२८
त	७३	१६
ती	५५	१७
त्य	७३	१६
न	१०७	१०२
र	१०४	६८
रदर्शिन्	६६	६
र्वा	४८	१'१८
षिका	५९	६७
हद	६४	१२०
छ्या	७६	४२
दृढ	८ १०५ ११५	७१ ७६ ४५
दृढसंधि	१०४	७५
दृति	१४१	१९
दृब्ध	१०५	८६
दृश्	६२	९३
दृषद्	३३	४
दृष्ट	७४	३०
दृष्टरजस्	५४	८

शब्दः	पृष्ठम्	श्लोकः
दृष्टान्त	११९	६२
दृष्टि	६२ ११६	९३ ३८
दृष्टेन्दु	१३	९
देव	१ २०	७ १३
देवकीनन्दन	३	२१
देवकुसुम	६५	१२५
देवखातक	२७	२७
देवखातबिल	३३	६
देवछन्द	६३	१०५
देवजग्धक	४९	१६६
देवतरु	६	५४
देवता	२	९
देवताड	४०	६९
देवत्व	७१	५२
देवतादारु	३८	५४
देवद्यङ्	१०१	३४
देवन	९७ १२४	४५ ११७
देववल्लभ	३६	२५
देवभूय	७१	५२
देवमातृक	३०	१२
देवयोनि	२	११
देवर	५६	३२
देवल	९४	११
देवशिल्पिन	११६	३५

शब्दः	पृष्ठम्
देवसभा	६
देवसायुज्य	७१
देवाजीव	९४
देवी	२० ४१ ४६
देवृ	५६
देश	३०
देशरूप	७४
देह	६०
देहली	३२
दैतेय	२
दैत्यगुरु	११
दैत्या	२
दैत्यारि	३
दैन्य	१२८
दैर्घ्य	६४
दैव	१५ ६८ ७१
दैवज्ञ	७३
दैवज्ञा	५५
दैवत	२ १४
दोला	४२ ७७
दोषज्ञ	६६
दोषा	१३८

शब्दः	पृष्ठम्	श्लोकः
	१०२	४६
	६०	८०
	२२	२७
	५५	२१
)	८	२
	१०	१७
	१२	३४
	११	३०
	९१	९०
	९७	४५
क	९७	४४
	९७	४४
:)	१	६
	८	१
	९२	३४
	८७	५१
	२२	३२
	८२	१११
	४१	८७
	८१	१०२
	९१	९०
	११८	५२
	१४२	२२
	९१	९०
	१२८	१५५
	१३८	२
	४३	१०७
	१०८	११२

शब्दः	पृष्ठम्	श्लोकः
द्राविडक	४३	१३५
द्रु	३४	५
द्रुकिलिम	३८	५३
द्रुघण	८०	९१
द्रुण	५०	१४
द्रुणी	१४१	९
द्रुत	७	६९
	१०६	८९
	१०७	१००
	१३८	२
द्रुम	३४	५
द्रुमामय	६५	१२५
द्रुमोत्पल	३९	६०
द्रुवय	९१	८५
द्रुहिण	२	१७
द्रोण	९१	८८
	११८	४८
द्रोणकाक	५१	२१
द्रोणक्षीरा	८९	७२
द्रोणदुग्धा	८९	७८
द्रोणी	२५	११
	४२	९५
द्रोहचिन्तन	१५	४
द्रौणिक	८४	१०
द्वन्द्व	५३	३८
	१३३	२१३
द्व्यातिग	७०	४५

शब्दः	पृष्ठम्	
द्वादशाङ्गुल	६१	
द्वादशात्मन्	११	
द्वापर	१५	
	१२९	१
द्वार्	३२	
द्वार	३२	
द्वारपाल	७२	
द्वाःस्थ	७२	
द्वाःस्थित	७२	
द्विगुणाकृत	८४	
द्विज	५२	
	११५	
द्विजराज	१०	१
द्विजा	४४	१२
द्विजाति	६६	
द्विजिह्व	१२६	१३
द्वितीया	५४	
द्विप	७५	३
द्विपाद्य	७४	२
द्विरद	७५	३
द्विरेफ	५२	२
द्विष्	७३	१
द्विषत्	७३	१
द्विसात्य	८४	
द्विहल्य	८	
द्विहायनी	८९	६
द्वीप	२५	

दः	पृष्ठम्	श्लोकः
त्रती	२७	३०
पिन्	४९	१
ण	७३	१०
य	१०२	४५
य	७३	१८
र	७७	५३
मातुर	५	४१
यष्ट	९२	९७
	ध	
ट	१४१	१७
त्तूर	४०	७७
न	९१	९०
धनञ्जय	६	५७
धनद	८	७३
धनहरी	४५	१२८
धनाधिप	८	७३
धनिन्	९९	१०
धनिष्ठा	११	२२
धनुःपट	३७	३५
धनुर्धर	७८	६९
धनुष्मान्	७८	६९
धनुस्	७९	८३
धन्य	९८	३
धन्व	७९	८३
धन्वन्	२९	५
धन्वयास	४२	९१
धन्विन्	७८	६९

शब्दः	पृष्ठम्	श्लोकः
धमन	४८	१६२
धमनि	५९	६५
धमनी	४५	१३०
धम्मिल्ल	६२	९७
धर	३३	१
धरणि	२९	२
धरा	२९	२
धरित्री	२९	२
धर्म	१४ १७ १२६	२४ ३ १३९
धर्मचिन्ता	२२	२८
धर्मध्वजिन्	७१	५४
धर्मपत्तन	८६	३६
धर्मराज	२ ७ ११६	१३ ६२ ३१
धर्मसंहिता	१७	६
धर्षिणी	५४	१०
धव	५६ १३३	३५ २०७
धवल	१६	१३
धवला	८९	६७
धवित्र	६८	२३
धातकी	४५ १४०	१२४ ७
धातु	३३ ११९	८ ६५

शब्दः	पृष्ठम्
धातुपुष्पिका	४
धातृ	२
धात्री	१३०
धाना	८७
धानुष्क	७८
धान्य	८५
धान्यत्वच्	८५
धान्याक	८६
धान्यांश	११७
धान्याम्ल	८६
धामन्	१२५
धामार्गव	४१ ४४
धाय्या	६८
धारणा	७४
धारा	७६
धाराधर	९
धारासम्पात	१०
धार्तराष्ट्र	५१
धावनी	४२
धिक्	१३६
धिक्कृत	१०१ १०६
धिषण	११
धिषणा	१५
धिष्ण्य	१२८
धी	१५

पृष्ठम्	श्लोकः	शब्दः	पृष्ठम्	श्लोकः	शब्दः	पृष्ठम्
१६	८	धूलि	८१	९८	ध्वाङ्क्ष	५१
६६	६	धूसर	१६	१३		१३४
५४	१२	धृति	१२०	७४	ध्वान	१९
६४	१२४	धृष्ट	१००	२५	ध्वान्त	२३
६६	५	धृष्णज्	१००	२५		**न**
२६	१५	धेनु	८९	७१	न	१३९
११०	२४	धेनुका	७५	३६	नकुलेष्टा	४४
७२	४		११३	१५	नक्तक	६४
१०६	८७	धेनुष्या	८९	७२	नक्तम्	१३८
२७	३०	धेनुक	८८	६०	नक्तमाल	३८
७७	५५	धैवत	१९	१	नक्र	२६
८९	६५	धोरण	७७	५८	नक्षत्र	१०
८९	६५	धौतकौशय	६३	११३	नक्षत्रमाला	६३
८९	६५	धौरितक	७६	४८	नक्षत्रेश	१०
१०७	१०७	धौरेय	८९	६५	नख	४५
१०७	१०२	ध्याम	४९	१६६		६१
१०७	१०२	ध्रुव	१०	२०	नखर	६१
११८	५८		३४	८	नग	११४
९	७		१०४	७२	नगरी	३१
१६	१६		१३३	२११	नगौकस्	५२
११२	४३	ध्रुवा	४४	११५	नग्न	१०१
५१	१६		६८	२५	नग्नहु	९७
१६	१६	ध्वज	८१	९९	नग्निका	५४
४	३६	ध्वजिनी	७९	७८	नट	३९
४०	७७	ध्वनि	१९	२२		९४
१०२	४७	ध्वनित	१०६	९४	नटन	२०
८९	६५	ध्वस्त	१०७	१०४	नटी	४५

ः	पृष्ठम्	श्लोकः
	४८	१६२
	४८	१६५
	१४३	३३
प्राय	३०	९
संहति	४९	१६८
ड्या	४९	१६८
ड्वत्	३०	९
ड्वल	३०	९
त	१०४	७१
तनासिक	५७	४५
द	११८	५७
दी	२७	२९
दीमातृक	३०	१२
दीसर्ज	३८	४५
ध्री	९६	३१
ननान्दृ	५६	२९
ननु	१३७	२४९
	१३९	१४
नन्दक	४	३०
नन्दन	५	४९
नन्दिवृक्ष	४५	१२८
नन्द्यावर्त	३२	१०
नपुंसक	५७	३९
नप्त्री	५६	२९
नभस्	८	१
	१४	१६
	१३५	२३३

शब्दः	पृष्ठम्	श्लोकः
नभसंगम	५२	३४
नभस्य	१४	१७
नभस्वत्	७	६७
नमस्	१३९	१८
नमसित	१०७	१०१
नमस्कारी	४६	१४१
नमस्या	६९	३५
नमस्यित	१०७	१०१
नमुचिसूदन	५	४७
नय	१०९	९
नयन	६२	९३
नर	५३	१
नरक	२४	१
नरवाहन	८	७३
नर्तक	२०	११
नर्तकी	२०	८
नर्तन	२०	१०
नर्मदा	२७	३२
नर्मन्	२२	३२
नलकूबर	८	७४
नलद	४८	१६४
नलमीन	२६	१८
नलिन	२८	३९
नलिनी	२८	३९
नली	४५	१२९
नल्व	३१	१८
नव	१०५	७७

शब्दः	पृष्ठम्
नवदल	२८
नवनीत	८८
नवमालिका	४०
नवसूतिका	८९
नवाम्बर	६३
नवीन	१०५
नवोद्धृत	८८
नव्य	१०५
नष्ट	८२
नष्टचेष्टता	२२
नष्टाग्नि	७१
नष्टेन्दुकला	१३
नस्तित	८९
नस्योत	८९
नहि	१३९
ना	१३९
नाक	१
	८
	११२
नाकु	३०
नाकुली	४४
नाग	२३
	७५
	९२
	१०३
	११४
नागकेसर	३९

शब्दः	पृष्ठम्	श्लोकः
ह्विका	९३	१०८
ा	४४	११७
	८६ १३१	३८ १८८
	३७	३८
क	२३	१
	४४	१२०
मत्र	९२	१०५
क	४	३२
	२०	१०
स	९४	८
	५९ ८५ ११७	६५ २२ ४३
	५८	५४
	९९	१६
	१९	२३
	३६ ३७ ३९ ४४	३० ३८ ६५ ११८
	१३७ १३८	२४८ ३
	१०६	९३
र	१०१	३८
ादिन्	१०१	३८
	९४	१०

शब्दः	पृष्ठम्	श्लोकः
नाभि	७७ १२६ १४१ १४२	५६ १३६ ९ २०
नाम	१३७	२५२
नामधेय	१७	८
नामन्	१७	८
नाय	१०९	९
नायक	९९	११
नारक	२४ २४	१ २
नारद	६	५२
नाराच	८०	८७
नाराची	९६	३२
नारायण	२	१८
नारायणी	४३	१०१
नारी	५३	२
नाल	२८ २८ ८५	४२ ४२ २२
नालिकेर	४९	१६८
नाविक	२५	१२
नाव्य	२५	१०
नाश	८२	११६
नासत्य	६	५५
नासा	३२ ६१	१३ ८९

शब्दः	पृष्ठम्
नासिका	६१
नास्तिकता	१५
निःशलाक	७४
निःशेष	१०४
निःशोध्य	१०३
निःश्रेयस	१६
निःषमम्	१३९
निःसरण	३२
निःस्व	१०२
निःस्वन	१९
निःस्वान	१९
निकट	१०४
निकर	५३
निकर्षण	३२
निकष	९६
निकषा	१३८ १३९
निकषात्मज	७
निकामम्	८८
निकाय	५३
निकाय्य	३१
निकार	१०९ १११
निकारण	८२
निकुञ्चक	९१
निकुञ्ज	३३
निकुम्भ	४७

शब्दः	पृष्ठम्	श्लोकः
कुरम्ब	५३	४०
कृत	१०१ १०२	४१ ४६
कृति	२२	३०
कृष्ट	१०३	५४
केतन	३१	४
कोचक	३६	२९
क्कण	१९	२४
क्काण	१९	२४
खिल	१०४	६५
निगड	७५	४१
निगद	१०९	१२
निगम	३१ १२६	१ १४०
निगाद	१०९	१२
निगार	१११	३७
निगाल	७६	४८
निग्रह	१०९	१३
निघ	१११	३६
निघास	८८	५६
निघ्न	९९	१६
निचुल	३९	६१
निचोल	६४	११६
निज	११६	३२
नितम्ब	३३ ६०	५ ७४
नितम्बिनी,	५३	२
नितान्त	८	७१
नित्य	७ १०४	७० ७२
निदाघ	१४ २२	१९ ३३
निदान	१५	२८
निदिग्ध	१०६	८९
निदिग्धिका	४२	९३
निदेश	७४ १३०	२५ १८०
निद्रा	२३	३६
निद्राण	१०१	३३
निद्रालु	१०१	३३
निधन	८२ १२५	११६ १२३
निधि	८	७६
निधुवन	७२	५७
निध्यान	१११	३१
निनद	१९	२२
निनाद	१९	२२
निन्दा	१८	१३
निप	८६	३२
निपठ	१११	२९
निपाट	१११	२९
निपातन	११०	२७
निपान	२७	२६
निपुण	९८	४
निबन्ध	५८	
निबन्धन	२०	
निबर्हण	८०	
निभ	९३	
निभृत	१००	
निमय	९०	
निमित्त	१२०	
निमेष	१३	
निम्न	२६	
निम्नगा	२७	
निम्ब	३९	
निम्बतरु	३६	
नियति	[illegible]	
नियन्तृ	७७	
नियम	[illegible] ७० ७१	
नियामक	२५	
नियुत	१४२	
नियुद्ध	८१	
नियोज्य	९५	
निर्	१३७	
निरन्तर	१०४	
निरय	२४	
निरर्गल	१०५	
निरर्थक	१०५	
निरवग्रह	९९	

	पृष्ठम्	श्लोकः
	१११	३१
	१८ ८० १०१	२० ८८ ४०
रिष्णु	१००	३०
त	१०१	४०
ति	७१ १११	५४ ३१
य	५८	५७
	८४	१३
	२४	२
	४० ४०	६८ ७०
न	८२	११३
	१९	२३
	१	७
न्द्रियग्राम	७०	४४
	३३	५
	१५	३
	१०३	५६
	९४	१०
	७४	२५
	८ १३८	७१ २
	७५	३६
	२३	६
	२४	९

शब्दः	पृष्ठम्	श्लोकः
निर्याण	७५	३८
निर्यातन	१२४	१२०
निर्यास	१२८	१५३
निर्वपण	६९	३०
निर्वर्णन	१११	३१
निर्वहण	२१	१५
निर्वाण	१६ १०६	६ ९६
निर्वात	१०६	९६
निर्वाद	१८ १२२	१३ ९०
निर्वापण	८२	११४
निर्वार्य	९९	१३
निर्वासन	८२	११३
निर्वृत्त	१०७	१००
निर्वेश	९७ ११० १३४	३९ २० २१५
निर्व्यथन	२३	२
निर्व्यूह	३६	१२३७
निर्हार	१०९	१७
निर्हारिन्	१६	११
निर्ह्राद	१९	२३
निलय	३१	५
निवह	५३	३९
निवात	१२१	८४
निवाप	६९	३१

शब्दः	पृष्ठम्
निवीत	६३ ७१
निवृत	१०६
निवेश	७५
निशा	१२
निशाख्या	८६
निशान्त	३१
निशापति	१०
निशित	१०६
निशीथ	१३
निशीथिनी	१२
निश्रय	१५
निश्रेणि	३२
निषङ्ग	८०
निषङ्गिन्	७८
निषद्या	३१
निषद्वर	२५
निषध	३३
निषाद	१९ ९५
निषादिन्	७७
निषूदन	८२
निष्क	११३
निष्कला	५५
निष्कासित	१०१
निष्कुट	३४
निष्कुटि	४५

शब्दः	पृष्ठम्	श्लोकः
ष्कुह	३५	१३
ष्क्रम	११०	२५
ष्ठा	२१	१५
	११७	४१
ष्ठान	८७	४४
	१२४	११६
ष्ठीवन	१११	३८
निष्ठुर	१८	१९
	१०५	७६
निष्ठ्यूत	१०६	८७
निष्ठ्यूति	१११	३८
निष्ठेव	१११	३८
निष्ठेवन	१११	३८
निष्णात	९८	४
निष्पक्व	१०६	९५
निष्पातिसुता	५४	११
निष्पन्न	१०७	१००
निष्पाव	११०	२४
निष्प्रभ	१०७	१००
निष्प्रवाणि	६३	११२
निसर्ग	२३	३८
निसृष्ट	१०६	८८
निस्तल	१०४	६९
निस्तर्हण	८२	११४
निस्त्रिंश	८०	८९
निस्राव	८७	४९
निहनन	८२	११४

शब्दः	पृष्ठम्	श्लोकः
निहाका	२६	२२
निहिंसन	८२	११३
निहीन	९४	१६
निह्नव	१८	१७
	१३३	२०९
नीकाश	९६	३८
नीच	९४	१६
	१०४	७०
नीचैस्	१३९	१७
नीड	५३	३७
नीडोद्भव	५२	३४
नीध्र	३२	१४
नीप	३७	४२
नीर	२५	४
नील	१६	१४
नीलकण्ठ	५२	३०
	११७	३९
नीलङ्गु	५०	१३
नीललोहित	४	३६
नीला	५२	२६
नीलाम्बर	३	२५
नीलाम्बुजन्मन्	२८	३७
नीलिका	४०	७०
नीलिनी	४२	९५
नीली	४२	९४
नीवाक	११०	२३
नीवार	८५	२५

शब्दः	पृष्ठम्
नीवी	९०
	१३३
नीवृत्	३०
नीशार	६४
नीहार	१०
नु	१३७
नुति	१८
नुत्त	१०६
नुन्न	१०६
नूतन	१०५
नूत्न	१०५
नूनम्	१३७
	१३९
नूपुर	६३
नृ	५३
नृत्य	२०
नृप	७२
नृपलक्ष्मन्	७५
नृपसभ	१४२
नृपासन	७५
नृशंस	१०२
नृसेन	१४४
नेतृ	९९
नेत्र	६२
	१३०
नेत्राम्बु	६२
नेदिष्ठ	१०४

	पृष्ठम्	श्लोकः
	६२	९९
	२७ ७७	२७ ५६
	३६	२६
	१०५	८३
	९० १२७	७८ १४०
	८९	६७
	९३	१०८
	९०	८०
	३५	१८
	७ ९	६४ २
	७२	७
क	७८	७०
	१३९	११
	२५	१०
ड	२५	१३
	२५	१०
	१३५	२२५
	३६ १२२	३२ ९६
	४१	८७
	१०४	७०
	५०	१०
	१०६	८८
	८८	५६

शब्दः	पृष्ठम्	श्लोकः
न्याय	७४	२४
न्याय्य	७४ १२८	२५ १६१
न्यास	९०	८१
न्युब्ज	५९	६१
न्यूंख	१४१	१७
न्यून	१२५	१२८
प		
पक्कण	३३	२०
पक्क	१०६ १०६	९१ ९६
पक्ष	१३ ५२ ६२ ८० १३४	१२ ३६ ९८ ८७ २२०
पक्षक	३२	१४
पक्षति	१२ ५२ १२०	१ ३६ ७२
पक्षद्वार	३२	१४
पक्षभाग	७५	४०
पक्षमूल	५२	३६
पक्षान्त	१३	७
पक्षिन्	५२	३२
पक्षिणी	१२	५
पक्ष्मन्	१२४	१२१

शब्दः	पृष्ठम्
पङ्क	१४ २५
पङ्किल	३०
पङ्केरुह	२८
पङ्क्ति	३४ ९० १२०
पङ्गु	५७
पचंपचा	४३
पचा	१०९
पञ्चजन	५३
पञ्चता	८२
पञ्चदशी	१३
पञ्चम	१९
पञ्चलक्षण	१७
पञ्चशर	३
पञ्चशाख	६१
पञ्चाङ्गुल	३८
पञ्चास्य	४९
पञ्चिका	१४०
पट	३७ ६४
पटच्चर	६४
पटल	३२ १३२
पटलप्रान्त	३२
पटवासक	६६

:	पृष्ठम्	श्लोकः
	२०	६
	८२	१०८
	४८	१५५
	९५	१९
	१०१	३५
	११६	४०
पर्णी	४६	१३८
ल	४८	१५५
लिका	४४	११८
ः	१४१	१७
ट्टिका	३७	४१
ट्टिन्	३७	४१
ट्टिश	१४२	२१
ण	९१	८८
	९७	३९
	९७	४५
	११७	४६
णव	२०	८
णायित	१०८	१०९
णित	१०८	१०९
णितव्य	९०	८२
ण्ड	५७	३९
ण्डित	६६	५
पण्य	९०	८२
पण्यवीथिका	३१	२
पण्या	४७	१५०
पण्याजीव	९०	७८
पतग	५२	३३

शब्दः	पृष्ठम्	श्लोकः
पतङ्ग	५२	२८
	११४	२०
पतङ्गिका	५२	२७
पतत्	५२	३२
पतत्र	५२	३६
पतत्रि	५२	३३
पतत्रिन्	५२	३३
पतद्ग्रह	६६	१३९
	१४२	२१
पतयालु	१००	२७
पताका	८१	९९
पताकिन्	७८	७१
पति	५६	३५
	९९	१०
पतिंवरा	५४	७
पतिवत्नी	५४	१२
पतिव्रता	५४	६
पत्तन	३१	१
पत्ति	७८	६६
	७९	८०
	१२०	७२
पत्तिसंहति	७८	६७
पत्नी	५४	५
पत्र	३५	१४
	५२	३६
	७७	५८
	१३०	१७९
पत्रपरशु	९६	३३

शब्दः	पृष्ठम्
पत्रपाश्या	६३
पत्ररथ	५२
पत्रलेखा	६४
पत्राङ्ग	६५
	९३
पत्राङ्गुलि	६४
पत्रिन्	५०
	५२
	८०
	१२३
पत्रोर्ण	३९
	६३
पथिक	७३
पथिन्	३०
पथ्या	३९
पद्	६०
पद	१२२
पदग	७८
पदवी	३०
पदाजि	७८
पदाति	७८
पदिक	७८
पद्ग	७८
पद्धति	३१
पद्म	८
	२८
पद्मक	७५

	पृष्ठम्	श्लोकः
ारिणी	४७	१४६
भ	३	२०
	४७	१४५
	९१	९२
	३ ४२ ४७	२८ ८९ १४६
र	२७	२८
	४७	१४७
या	३	२८
	७५	३५
	१४३	३१
	३०	१५
	३९	६१
त	१०८	१०९
	१०८	१०९
	१०७	१०४
	२४	८
शान	४	३२
	२५ ८७ १३५	३ ५१ २३३
	८७	५१
र	१२९	१६४
	२५ ७३ १३१	८ ११ १९१

शब्दः	पृष्ठम्	श्लोकः
परजात	९५	१८
परतन्त्र	९९	१६
परपिण्डाद	९९	२०
परभृत्	५१	१९
परभृत	५१	१९
परमम्	१३९	१२
परमान्न	६८	२४
परमेष्ठिन्	२	१६
परम्पराक	६८	२६
परवत्	९९	१६
परशु	८०	९२
परश्वध	८०	९२
परश्वस्	१४०	२२
पराक्रम	८१ १२६	१०२ १२८
पराग	३५ ११४	१७ २१
पराङ्मुख	१०१	३३
पराचित	९५	१८
पराचीन	१०१	३३
पराजय	८२	१११
पराजित	८२	११२
पराधीन	९९	१६
परान्न	९९	२०
पराभूत	८२	११२
परारि	१३९	२०
परार्ध्य	१०३	५८

शब्दः	पृष्ठम्
परासन	८२
परासु	८२
परास्कान्दिन्	९५
परिकर	१२९
परिकर्मन्	६४
परिक्रम	१०९
परिक्रिया	११०
परिक्षिप्त	१०६
परिखा	२७
परिग्रह	१३६
परिघ	८० ११५
परिघातिन्	८०
परिचय	११०
परिचर	७७
परिचर्या	६९
परिचाय्य	६८
परिचारक	९५
परिणत	१०६
परिणय	७२
परिणाम	१०९
परिणाय	९७
परिणाह	६४
परितस्	१३९
परित्राण	१०८
परिदान	९०
परिदेवन	१८

ः	पृष्ठम्	श्लोकः
ान	६४	११७
थे	१२ १२२	३२ ९७
धस्थ	७७	६२
ण	९०	८०
ान्थिन्	७३	११
पाटी	७०	३७
पूर्णता	६६	१३७
पेलव	४५	१३१
त्र	१०४	७५
बर्ह	१३६	२३९
भव	२१	२२
भाषण	१८	१४
भूत	१०७	१०६
रिमळ	१६ १०९	१० १३
रम्भ	१११	३०
रिवर्जन	८२	११४
रिवादिनी	२०	३
रिवापित	१०५	८५
रिवित्ति	७१	५६
रिवृढ	९९	११
रिवेत्तृ	७१	५६
रिवेष	१२	३२
रिव्याध	३६ ३९	३० ६०
रिव्राज्	७०	४२

शब्दः	पृष्ठम्	श्लोकः
परिषद्	६७	१५
परिष्कार	६२	१०१
परिष्कृत	६२	१००
परिष्वङ्ग	१११	३०
परिसर	३०	१४
परिसर्प	११०	२०
परिसर्या	११०	२१
परिस्कन्द	९५	१८
परिस्तोम	७६	४२
परिस्यन्द	६६	१३७
परिस्रुत्	९७	३९
परिस्रुता	९७	४०
परीक्षक	९८	७
परीभाव	२१	२२
परीवर्त	९०	८०
परीवाद	१८	१३
परीवाप	१२५	१२९
परीवार	१२९	१६९
परीवाह	२५	१०
परीष्टि	६९	३२
परीसार	११०	२१
परीहास	२२	३२
परुत्	१३९	२०
परुष	१८	१९
परुस्	४८	१६२
परेत	८२	११७
परेतराज्	७	६२

शब्दः	पृष्ठम्
परेद्यवि	१४०
परेष्टुका	८९
परैधित	९५
परोष्णी	५१
पर्कटी	३६
पर्जनी	४३
पर्जन्य	१२७
पर्ण	३५ ३६ १४२
पर्णशाला	३१
पर्णास	४१
पर्यङ्क	६६
पर्यटन	६९
पर्यन्तभू	३०
पर्यय	७० १११
पर्यवस्था	११०
पर्याप्त	८८
पर्याप्ति	१०८
पर्याय	७० १२७
पर्यायशय	१११
पर्युदञ्चन	८३
पर्येषणा	३९
पर्वत	३३
पर्वन्	४८ १२४

	पृष्ठम्	श्लोकः
धि	१३	७
ा	५९	६९
	९१ १३२	८६ २०२
ड	९४	६
कषा	४२	९८
	५९	५३
डु	४७	१४७
ठ	८५	२२
ा	३५ ३६ ४७	१४ २९ १५४
शिन्	३५	५
ती	५४	१२
ा	५७	४१
ङ्क	६६	१३८
	३५	१४
ळ	२७	२८
	११०	२४
	७ ११०	६७ २४
शन	२४	८
ान	७	६७
	३	५१
ा	४९ ७० १०३	१६६ ४५ ५५

शब्दः	पृष्ठम्	श्लोकः
पवित्रक	२६	१६
पशुपति	४	३३
पशुप्रेरण	१११	३९
पशुरज्जु	८९	७३
पश्चात्	१३६	२४३
पश्चात्ताप	२२	२५
पश्चिम	१०५	८१
पश्चिमा	८	१
पश्चिमोत्तर	३०	७
पस्त्य	३१	५
पांशुला	५४	९१
पांसु	८१	९८
पाक	५३ १०९	३८ ८
पाकल	४५	१२६
पाकशासन	५	४५
पाकशासनि	६	५०
पाकस्थान	८५	२७
पाक्य	८७ ९३	४२ १०९
पाखण्ड	७०	४५
पाञ्चजन्य	४	२९
पाञ्चालिका	९६	२९
पाट्	१३८	७
पाटच्चर	९५	२५
पाटल	१६ ८४	१५ १५

शब्दः	पृष्ठम्	
पाटला	३५ ३८	
पाटलि	३७ ३८	
पाठ	६७ १११	
पाठा	४१	
पाठिन्	४१	
पाठीन	२६	
पाणि	६१	
पाणिगृहीती	५४	
पाणिघ्न	९४	
पाणिपीडन	७२	
पाणिवाद	९४	
पाण्डु	१६	
पाण्डुकम्बलिन्	७७	
पाण्डुर	१६	
पातक	१४३	
पाताल	२३ १३२	 २
पातुक	१००	
पात्र	२५ ६८ ८६ १३०	 १
पात्री	१४४	
पात्रीव	१४३	
पाथस	२५	

	पृष्ठम्	श्लोकः
	३३ ६० ९१ १२१	७ ७१ ८९ ८९
कटक	६३	११०
ग्रहण	७०	४१
प	३४	५
बन्धन	८८	५८
दस्फोट	५८	५२
दाग्र	६०	७१
दात	७८	६८
दातिक	७८	६७
दुका	९६	३०
दू	९६	३१
दूकृत्	९४	७
नगोष्ठिका	९७	४३
नपात्र	९७	४३
नभाजन	८६	३२
नीय	२५	४
नीयशालिका	३१	७
न्थ	७३	१७
पाप	१४ १०२	२३ ४७
पापचेली	४१	८५
पाप्मन्	१४	२३
पामन्	५८	५३
पामन	५८	५८

शब्दः	पृष्ठम्	श्लोकः
पामर	९४	१६
पामा	५८	५३
पायस	६५ ६८	१२८ २४
पायु	६०	७३
पाग्य	९१	८५
पार	२५	८
पारद	९२	९९
पारंपर्योपदेश	६७	१२
पारशव	१३३	२११
पारश्वधिक	७८	७०
पारसीक	७६	४५
पारस्त्रैणेय	५५	२४
पारायण	१०८	२
पारावत	५०	१४
पारावताङ्घ्रि	४७	१५०
पारावार	२४ १४३	१ ३५
पाराशरिन्	७०	४२
पारिकांक्षिन्	७०	४२
पारिजातक	६ ३६	५४ २६
पारितथ्या	६३	१०३
पारिप्लव	१०४	७५
पारिभद्र	३६	२६
पारिभद्रक	३८	५३
पारिभाव्य	४५	१२६

शब्दः	पृष्ठम्
पारियात्रिक	३३
पारिषद	४
पारिहार्य	६३
पारी	१४१
पारुष्य	१८
पार्थिव	७२
पार्वती	५
पार्वतीनन्दन	५
पार्श्व	६० ११२
पार्श्वभाग	७५
पार्श्वास्थि	५९
पार्ष्णि	६०
पार्ष्णिग्राह	७३
पालघ्न	४९
पालङ्की	४४
पालाश	१६
पालि	८० १३२
पालिन्दी	४३
पावक	६
पाश	६२
पाशक	९७
पाशिन्	७
पाशुपत	४१
पाशुपाल्य	८३
पाश्चात्य	१०५

शब्दः	पृष्ठम्	श्लोकः
	११२	४३
	३३	४
रण	९६	३४
	५१	१९
	१६	१६
	१२	३१
	१६	१६
	९	४
	६०	७७
	१४१	१८
ल	५७	४४
	९२	१०६
र	३९	६२
	३७	४०
	९२	१०५
	५२	३१
	१४३	३०
	३८	४७
	१४१	९
ह	८७	४६
ला	३८	४६
	३९	६२
	८२	११५
	९२	१०३
	१४३	३१
	८१	९९
	८५	२६

शब्दः	पृष्ठम्	श्लोकः
पिटक	५८	५३
	९६	३०
पिठर	८६	३१
	१३३	१८८
पिण्ड	९२	१०४
	९२	९८
	१४१	१८
पिण्डक	६५	१२८
पिण्डीतक	३८	५२
पिण्याक	११३	९
	१४३	३२
पितरौ	५६	३७
पितामह	२	१६
	५६	३३
पितृ	५६	२८
पितृदान	३९	३१
पितृपति	७	६२
	९	२
पितृपितृ	५६	३३
पितृप्रसू	१२	३
पितृवन	८२	११८
पितृव्य	५६	३१
पितृसान्निभ	९९	१३
पित्त	५९	६२
पित्सत्	५२	३४
पिधान	१०	१३
पिनद्ध	७८	६५

शब्दः	पृष्ठम्	श्लो
पिनाक	४	
	११३	
पिनाकिन्	४	
पिपासा	८८	५
पिप्पल	३५	
पिप्पली	४२	९
पिप्पलीमूल	९३	११
पिप्लु	५८	४
पिशङ्ग	१६	१
पिशाच	२	१
पिशित	५९	६
पिशुन	६४	१२
	१०२	४
	१२५	१२
पिशुना	४६	१३
पिष्टक	८७	४
पिष्टपचन	८६	२
पिष्टात	६६	१३
पीठ	६६	१२
पीडन	८२	१०
पीडा	२४	
पीत	१६	१
पीतदारु	३८	५
पीतद्रु	३९	६
	४३	१०
पीतन	३६	२
	६४	१२
	९२	१०

ब्दः	पृष्ठम्	श्लोकः
ीतसारक	३७	४३
ीता	८६	४१
ीताम्बर	३	१९
ीन	१०३	६१
ीनस	५८	५१
ीनोध्नी	८९	७१
पीयूष	६ ८८	५२ ५४
पीलु	३६ १३२	२८ १९४
पीलुपर्णी	४१ ४६	८४ १३९
पीवन्	१०३	६१
पीवर	१०३	६१
पीवरस्तनी	८९	७१
पुंश्चली	५४	१०
पुक्कस	९५	२०
पुङ्ख	१४१	१७
पुङ्गव	१०३	५९
पुच्छ	७६	५०
पुञ्ज	५३	४२
पुटभेद	२५	७
पुटभेदन	३१	१
पुटी	१४४	४२
पुण्डरीक	९ २८ ११३	३ ४१ ११

शब्दः	पृष्ठम्	श्लोकः
पुण्डरीकाक्ष	३	१९
पुण्ड्र	४८	१६३
पुण्ड्रक	४०	७२
पुण्य	१४ १२८	२४ १६०
पुण्यक	७०	३८
पुण्यजन	७	६४
पुण्यजनेश्वर	८	७४
पुण्यभूमि	३०	८
पुण्यवत्	९८	३
पुत्तिका	५२	२७
पुत्र	५६	२७
पुत्रिका	९६	२९
पुत्रौ	५६	३७
पुद्गल	१४२	२०
पुनःपुनर्	१३८	१
पुनर्	१३७ १३९	२५३ १५
पुनर्नवा	४७	१४९
पुनर्भव	६१	८३
पुनर्भू	५५	२३
पुन्नाग	३६	२५
पुमस्	५३	१
पुर्	३१	१
पुर	३७ १३१	२४ १८४
पुरःसर	७८	७२

शब्दः	पृष्ठम्
पुरतस्	१३८
पुरद्वार	३२
पुरन्दर	५
पुरन्ध्री	५४
पुरस्	१३८
पुरस्कृत	१२१
पुरस्तात्	१३७
पुरा	१३७
पुराण	१७ १०५
पुरातन	१०५
पुरावृत्त	१७
पुरी	३१
पुरीतत्	५९
पुरीष	५९
पुरु	१०३
पुरुष	१५ ३६ ५३ १३४
पुरुषोत्तम	३
पुरुहू	१०३
पुरुहूत	५
पुरोग	७८
पुरोगम	७८
पुरोगामिन्	७८
पुरोडाश	१४२

	पृष्ठम्	श्लोकः
	७२	५
ान्	१०२	४६
	७२	५
	११२	५
	२५	९
	९५	२०
ा	५	४९
	१०६	९७
	८	१
	२५	४
	२८	४१
	४७	१४५
	१३१	१८६
	५१	२२
ी	२७	२७
	१०३	५८
	१०६	९७
	३५	१७
	५५	२१
	१४२	२३
	८	७५
	९२	१०३
	९२	१०३
ा	९	४
वन्	३	२७
	३५	२१
	७६	५१

शब्दः	पृष्ठम्	श्लोकः
पुष्परस	३५	१७
पुष्पलिङ्	५२	२९
पुष्पवती	५५	२०
पुष्पवन्तौ	१३	१०
पुष्पसमय	१४	१८
पुष्य	१०	२२
	१२७	१४७
पुस्त	९६	२८
पूग	४९	१६०
	११४	२०
पूजा	६९	३५
पूजित	१०७	९८
पूज्य	९८	५
	१२८	१५१
पूत	७०	४५
	८५	२३
	१०३	५५
पूतना	३९	५९
पूतिक	३८	४८
पूतिकरज	३८	४८
पूतिकाष्ठ	३८	५४
	३९	६०
पूतिगन्धि	१६	१२
पूतिफली	४२	९६
पूप	८७	४८
पूर	१४२	२०
पूरणी	३८	४६

शब्दः	पृष्ठम्	श्लोक
पूरित	१०७	९
पूरुष	५३	
पूर्ण	१०४	६
	१०७	९
पूर्णकुम्भ	७५	३
पूर्णिमा	१३	
पूर्त	६९	२
पूर्व	१०५	८
	१२६	१३
पूर्वज	५७	४
पूर्वदेव	२	१
पूर्वपर्वत	३३	
पूर्वेद्युस्	१३९	२
पूषन्	११	२
पृक्ति	१०९	
पृच्छा	१७	१
पृतना	७९	७
	७९	८
पृथक्	१३८	
पृथक्पर्णी	४२	९
पृथगात्मता	१५	३
	७०	३
पृथग्जन	९४	१
	१२३	१०
पृथग्विध	१०७	९
पृथिवी	२९	

ब्दः	पृष्ठम्	श्लोकः
थु	८६	३७
	८६	४०
	१०३	६०
ृथुक	५३	३८
	८७	४७
	११२	३
पृथुरोमन्	२६	१७
पृथुळ	१०३	६०
पृथ्वी	२९	३
	८६	३७
	८६	४०
पृथ्वीका	४५	१२५
पृदाकु	२३	६
पृश्नि	५७	४८
पृश्निपर्णी	४२	९२
पृषत्	२५	६
पृषत	२५	६
	५०	१०
पृषत्क	८०	८६
पृषदश्व	७	६६
पृषदाज्य	६८	२४
पृष्ठ	६०	७८
पृष्ठवंशाधर	६०	७६
पृष्ठास्थि	५९	६९
पृष्ट्य	७६	४६
	११२	४२
पेचक	५०	१५
	११२	६

शब्दः	पृष्ठम्	श्लोकः
पेटक	९६	३०
पेटा	९६	३०
पेटी	१४४	४२
पेलव	१०४	६६
पेशल	९५	१९
	१३३	२०५
पेशी	५३	३७
पैठर	८७	४५
पैतृष्वसेय	५५	२५
पैतृष्वस्रीय	५५	२५
पोटगल	४८	१६२
	४८	१६३
पोटा	५४	१५
पोत	५३	३८
	११९	६०
पोतवणिज्	२५	१२
पोतवाह	२५	१२
पोताधान	२६	१९
पोत्र	१३०	१८१
पोत्रिन्	४९	२
पौण्डर्य	४५	१२७
पौत्री	५६	२९
पौर	४९	१६६
पौरस्त्य	१०५	८०
पौरुष	६१	८७
	१३४	२२३
पौरोगव	८५	२७

शब्दः	पृष्ठम्
पौर्णमासी	१३
पौलस्त्य	८
पौलि	८७
पौष	१३
प्याट्	१३८
प्रकाण्ड	१४
	३४
प्रकामम्	८८
प्रकार	१२९
प्रकाश	१२
	१३४
प्रकीर्णक	७५
प्रकीर्य	३८
प्रकृति	१५
	२३
	७३
	१२०
प्रकोष्ठ	६०
प्रक्रम	११०
प्रक्रिया	७५
प्रक्वण	१९
प्रक्वाण	१९
प्रक्ष्वेडन	८०
प्रगण्ड	६०
प्रगतजानुक	५७
प्रगल्भ	१००
प्रगाढ	११७

	पृष्ठम्	श्लोकः
	१०४	७२
	१३९	१९
	८३	११९
	१३६	२३७
	१३६	२३७
	१४३	३५
	३२	१२
	३२	१२
	८०	९६
त	१०१	३२
	१०३	६३
	७	६५
	४२	९४
	६४	११६
	३२	१४
	५८	५५
	११०	२५
	७८	७३
	११६	३२
	५५	१६
	२	१७
	५६	३०
	१५	१
	५४	१२
	१२५	१२२
	५७	४७
	५२	३७

शब्दः	पृष्ठम्	श्लोकः
प्रणय	११०	२५
	१२८	१५२
प्रणव	१७	४
प्रणाद	१८	११
प्रणाली	२८	३५
प्रणिधि	७३	१३
	१२२	१००
प्रणिहित	१०५	८६
प्रणीत	६८	२०
	८७	४५
प्रणुत	१०८	१०९
प्रणेय	१००	२५
प्रतन	१०५	७७
प्रतल	६१	८४
	६१	८५
प्रताप	७४	२०
प्रतापस	४१	८१
प्रति	१३७	२४५
प्रतिकर्मन्	६२	९९
प्रतिकूल	१०५	८४
प्रतिकृति	९६	३६
प्रतिकृष्ट	१०३	५४
प्रतिक्षिप्त	१०१	४२
प्रतिख्याति	११०	२८
प्रतिग्रह	७९	७९
प्रतिग्राह	६६	१३९
प्रतिघा	२२	२६

शब्दः	पृष्ठम्	श्लोक
प्रतिघातन	८२	११
प्रतिच्छाया	९६	३
प्रतिजागर	११०	२
प्रातिज्ञात	१०७	१०८
प्रतिज्ञान	१५	
प्रतिदान	९०	८१
प्रतिध्वान	१९	२५
प्रतिनिधि	९६	३६
प्रतिपत्	१२	१
	१५	१
प्रतिपन्न	१०७	१०८
प्रतिपादन	६९	२९
प्रतिबद्ध	१०१	४१
प्रतिबन्ध	११०	२७
प्रतिबिम्ब	९६	३६
प्रतिभय	२१	२०
प्रतिभान्वित	१००	२५
प्रतिभू	९७	४४
प्रतिमा	९६	६३
प्रतिमान	७५	३९
	९६	३५
प्रतिमुक्त	७८	६५
प्रतियत्न	१२३	१०७
प्रतियातना	९६	३६
प्रतिरोधि	९५	२५
प्रतिवाक्य	१७	१०
प्रतिविषा	४२	९९

ब्दः	पृष्ठम्	श्लोकः
ातिशासन	१११	३४
प्रतिश्याय	५८	५१
प्रतिश्रय	१२८	१५३
प्रतिश्रव	१५	५
प्रतिश्रुत्	१९	२५
प्रतिष्टम्भ	११०	२७
प्रतिसर	१३०	१७४
प्रतिसीरा	६४	१२०
प्रतिहत	१०१	४१
प्रतिहारक	९४	११
प्रतिहास	४०	७६
प्रतीक	६० ११२	७० ७
प्रतीकार	८२	११०
प्रतीकाश	९६	३८
प्रतीक्ष्य	९८	५
प्रतीची	८	१
प्रतीत	९८ १२१	९ ८२
प्रतीपदर्शिनी	५३	२
प्रतीर	२५	७
प्रतीहार	३२ १२९	१६ १७०
प्रतोली	३१	३
प्रत्न	१०५	७७
प्रत्यक्	१४०	२३
प्रत्यक्पर्णी	४२	८९

शब्दः	पृष्ठम्	श्लोकः
प्रत्यक्श्रेणी	४१ ४७	८८ १४४
प्रत्यक्ष	१०५	७९
प्रत्यग्र	१०५	७७
प्रत्यन्त	३०	७
प्रत्यन्तपर्वत	३३	७
प्रत्यय	१२७	१४८
प्रत्ययित	७३	१३
प्रत्यर्थिन्	७३	११
प्रत्यवसित	१०८	११०
प्रत्याख्यात	१०१	४०
प्रत्याख्यान	१११	३१
प्रत्यादिष्ट	१०१	४०
प्रत्यादेश	१११	३१
प्रत्यालीढ	७९	८५
प्रत्यासार	७९	७९
प्रत्याहार	१०९	१६
प्रत्युत्क्रम	११०	२६
प्रत्युषस्	१२	२
प्रत्यूष	१२	२
प्रत्यूह	११०	१९
प्रथम	१०५ १२७	८० १४४
प्रथा	१०९	९
प्रथित	९८	९
प्रदर	१२९	१६५
प्रदीप	६६	१३८

शब्दः	पृष्ठम्
प्रदीपन	२४
प्रदेशन	७४
प्रदेशिनी	६१
प्रदोष	१२
प्रद्युम्न	३
प्रद्राव	८२
प्रधन	८१
प्रधान	१५ ७२ १०३ १२५
प्रधि	७७
प्रपञ्च	११५
प्रपद	६०
प्रपा	३१
प्रपात	३३
प्रपितामह	५६
प्रपुन्नाड	४७
प्रपौण्डरीक	४४
प्रफुल्ल	३४
प्रबन्धकल्पना	१७
प्रबोधन	६४
प्रभञ्जन	७
प्रभव	१३३
प्रभा	१२
प्रभाकर	११
प्रभात	१२

	पृष्ठम्	श्लोकः
	७३	१९
	७४	२०
	७५	३६
	९९	११
	१०३	६३
	६५	१३५
	४	३८
	८२	११५
प	४	३४
	१४	२४
	३४	३
	५३	३
	९८	७
	१०९	१०
	११८	५४
	२२	३०
	८२	११२
	१०९	१०
	६८	२६
	८२	११७
	२३	३७
	१३०	१७६
	१०३	५७
	१०७	१०३
	१४	२४
	७०	४५
	८७	४५

शब्दः	पृष्ठम्	श्लोकः
प्रयाम	११०	२३
प्रयोगार्थ	११०	२६
प्रलम्बघ्न	३	२४
प्रलय	१४	२२
	२२	३३
	८२	११६
प्रलाप	१८	१५
प्रवण	११८	५६
प्रवयस्	५७	४२
प्रवर्ह	१०३	५७
प्रवह	११०	१८
प्रवहण	७६	५२
प्रवह्लिका	१७	६
प्रवारण	१०८	३
प्रवाल	२०	७
	९१	९३
	१३३	२०५
प्रवाह	११०	१८
प्रवासन	८२	११३
प्रवाहिका	५८	५५
प्रविदारण	८१	१०३
प्रविश्लेष	११०	२०
प्रवीण	९८	४
प्रवृत्ति	१७	७
	११०	१८
प्रवृद्ध	१०५	७६
	१०६	८८
	१२१	८५

शब्दः	पृष्ठम्	श्लो
प्रवेक	१०३	५
प्रवेणी	६२	९
	७६	४
प्रवेष्ट	६०	८
प्रव्यक्त	१०५	८
प्रश्न	१७	१
प्रश्रय	११०	२
प्रश्रित	१००	२
प्रष्ठ	७८	७
प्रष्ठवाह्	८९	६
प्रष्ठौही	८९	७
प्रसन्न	९६	१४
प्रसन्नता	१०	१६
प्रसन्ना	९७	४०
प्रसभ	८२	१०८
प्रसर	११०	२३
प्रसरण	८०	९६
प्रसव	१०९	१०
	१३३	२०८
प्रसवबन्धन	३५	१५
प्रसव्य	१०५	८४
प्रसह्य	१३९	१०
प्रसाद	१०	१६
	१२२	९१
प्रसाधन	६२	९९
प्रसाधनी	६६	१३९
प्रसाधित	६२	१८०

ब्दः	पृष्ठम्	श्लोकः
सारिणी	४७	१५२
सारिन्	१००	३१
सित	९८	९
सिति	१०९	१४
सिद्ध	१२३	१०४
सू	५६	२९
	१३५	२३०
सूता	५५	१६
प्रसूति	१०९	१०
प्रसूतिका	५५	१६
प्रसूतिज	२४	३
प्रसून	३५	१७
	१२५	१२३
प्रसूजनयितारौ	५६	३७
प्रसृत	१०६	८८
प्रसृता	६०	७२
प्रसृति	६१	८५
प्रसेव	८५	२६
प्रसेवक	२०	७
प्रस्तर	३३	४
	१२९	१६२
प्रस्ताव	११०	२४
प्रस्थ	३३	५
	९१	८९
	१२१	८८
प्रस्थपुष्प	४१	७९
प्रस्थमान	९१	८५

शब्दः	पृष्ठम्	श्लोकः
प्रस्थान	८०	९५
प्रस्फोटन	८५	२६
प्रस्रवण	३३	५
प्रस्राव	५९	६७
प्रहर	१३	६
प्रहरण	७९	८२
प्रहस्त	६१	८४
प्रहि	२७	२६
प्रहेलिका	१७	६
प्रह्लन्न	१०७	१०३
प्रांशु	१०४	७०
प्राक्	१३९	१६
	१४०	२३
प्राकार	३१	३
प्राकृत	९४	१६
प्राग्दक्षिण	३०	७
प्राग्वंश	६८	१६
प्राग्रहर	१०३	५८
प्राग्र्य	१०३	५८
प्राघार	१०९	१०
प्राघुणक	६९	३४
प्राघूर्णिक	६९	३४
प्राचिका	१४०	८
प्राची	८	१
प्राचीन	३१	३
प्रचीना	४१	८५

शब्दः	पृष्ठम्
प्राचीनावीत	७१
प्राच्य	३०
प्राजन	८४
प्राजितृ	७७
प्राज्ञ	६६
प्राज्ञा	५४
प्राज्ञी	५४
प्राज्य	१०३
प्राड्विवाक	७२
प्राण	७
	८१
	८३
	९२
प्राणिन्	१५
प्रातर्	१३९
प्राथमकल्पिक	६७
प्रादुस्	१३७
	१३९
प्रादेश	६१
प्रादेशन	६९
प्राध्वम्	१३८
प्रान्तर	३०
प्राप्त	१०५
	१०७
प्राप्तपञ्चत्व	८२
प्राप्तरूप	१२५
प्राप्ति	११९

	पृष्ठम्	श्लोकः
	१०६	९२
	७४	२७
	७१	५३
	१२८	१५४
	१३९	१७
	१०६	९७
व	६६	१३६
वका	६३	१०४
	१०	१८
ा	६४	११८
	६४	११७
	६३	११३
	१४	१९
ायणी	४१	८६
	८०	९३
	७७	५७
च	८९	६४
र	३२	९
क	७८	७०
	१२	४
	५६	३५
	१०२	५३
	३७	४२
	३७	४४
	३९	५६
	५०	९

शब्दः	पृष्ठम्	श्लोकः
प्रियङ्गु	३८	५५
	८५	२०
प्रियता	२२	२७
प्रियंवद	१०१	३६
प्रियाल	३७	३५
प्रीणन	१०८	४
प्रीत	१०७	१०३
प्रीति	१४	२४
प्रुष्ट	१०७	९९
प्रेक्षा	१५	१
	१३४	२२५
प्रेङ्खा	७७	५३
प्रेङ्खित	१०६	८७
प्रेत	८२	११७
	११९	६०
प्रेता	२४	२
प्रेत्य	१३८	८
प्रेमन्	२२	२७
	२२	२७
प्रेष्ठ	१०८	१११
प्रैष	१३४	२२०
प्रैष्य	९५	१७
प्रोक्षण	६८	२६
प्रोक्षित	६८	२६
प्रोथ	७६	४९
प्रोष्ठपदा	११	२२
प्रोष्ठी	२६	१८

शब्दः	पृष्ठम्	श्लो
प्रौष्ठपद	१४	
प्रौढ	१०५	
प्लक्ष	३६	
	३७	
प्लव	२५	
	२६	
	४५	१
	५२	
	९५	
प्लवग	४९	
	११५	
प्लवङ्ग	४९	
प्लवङ्गम	१२६	१
प्लाक्ष	३५	
प्लीहन्	५९	
प्लीहशत्रु	३८	
प्लुत	७६	
प्लुष्ट	१०७	
प्लोष	१०९	
प्सात	१०८	१

फ.

शब्दः	पृष्ठम्	श्लो
फणा	२४	
फणिज्जक	४१	
फणिन्	२३	
फल	८०	
	१३२	२
	१४३	

ः	पृष्ठम्	श्लोकः
लक	८०	९०
लकपाणि	७८	७१
लत्रिक	९३	१११
लपाक्रान्ता	३४	६
लपूर	४१	७८
लवत्	३४	७
लाध्यक्ष	३८	४५
लिन्	३४	७
लिन	३४	७
लिनी	३८ ४६	५५ १३६
ली	३८	५५
लेग्रहि	३४	६
लेरुहा	३८	५४
ल्गु	३९ १०३	६१ ५६
ाणित	८७	४३
ाण्ट	१०६	९४
ाल	६३ ८४	१११ १३
फाल्गुन	१३	१५
फाल्गुनिक	१३	१५
फाल्गुनी	१४०	६
फुल्ल	३४	८
फेन	९२ १४२	१०५ १९
फेनिल	३६ ३७	३१ ३६

शब्दः	पृष्ठम्	श्लोकः
फेरव	४९	५
फेरु	४९	५
फेला	८८	५६
	ब.	
बक	५१	२२
बकुल	३९	६४
बडिश	२६	१६
बत	१३६	२४४
बदर	३७	३७
बदरा	४४ ४७	११६ १५१
बदरी	३७	३६
बद्ध	१०१ १०६	४२ ९५
बधिर	५७	४८
बन्दिन्	८१	९७
बन्दी	८३	११९
बन्धकी	५४	१०
बन्धन	७४ १०९	२६ १४
बन्धु	५६	३४
बन्धुजीवक	४०	७३
बन्धुता	५६	३५
बन्धुर	१०४	६९
बन्धुल	५५	२६
बन्धूक	४०	७३
बन्धूकपुष्प	३७	४४

शब्दः	पृष्ठम्
बभ्रु	१२९
बर्बर	४२
बर्बरा	४६
बर्ह	५२ १३६
बर्हपुष्प	४५
बर्हिः	६
बर्हिण	५२
बर्हिन्	५२
बर्हिर्मुख	२
बर्हिष्ठ	४५
बल	३ ७९ ८१ १३२ १४२
बलदेव	३
बलभद्र	३
बलभद्रिका	१५०
बलवत्	५७ १३८
बलविन्यास	७९
बला	४३
बलाका	५१
बलात्कार	८२
बलाराति	५
बलाहक	९

	पृष्ठम्	श्लोकः
	६७	१४
	७४	२७
	१३२	१९५
सिन्	३	२१
	५७	४५
	५१	२०
	५७	४५
	५१	२०
	५८	४९
न्	२३	१
	८८	५९
	८५	२७
	८८	५७
	४८	१६३
र्णा	८९	७१
	९०	७६
	६०	७३
	३२	१६
	१०८	१११
	१३९	१७
	१०३	६३
	९९	१७
वाक्	१०१	३६
	३६	३२
	९८	६
र	६३	११२
	६७	१२८

शब्दः	पृष्ठम्	श्लोकः
बहुल	१०३	६३
	१०८	११२
	१३२	१९९
बहुला	४५	१२५
बहुलीकृत	८५	२३
बहुवारक	३७	३४
बहुविध	१०६	९३
बहुवेतस	३०	९
बहुसुता	४३	१००
बहुसूति	८९	७०
बाकुची	४२	९६
बाढ	८	७१
	११७	४४
बाण	८०	८६
	११७	४५
बाणा	४०	७४
बादर	६३	१११
बाधा	२४	३
बान्धकिनेय	५५	२६
बान्धव	५६	३४
बार्हत	३५	१९
बाल	४५	१२२
	५७	४२
	१३३	२०६
बालगर्भिणी	८९	७०
बालतनय	३८	४९
बालतृण	४९	१६७

शब्दः	पृष्ठम्	श्लो
बालमूषिका	५०	९
बाला	२१	९
बालिश	१०२	४
	१३४	२९
बालेय	९०	७
बालेयशाक	४२	९
बाल्य	५७	४
बाष्प	१२५	१३
बाष्पिका	८६	४
बाहु	६०	८
बाहुत्र	७२	
बाहुदा	२७	३
बाहुमूल	६०	७
बाहुयुद्ध	८१	१०
बाहुल	१४	१
बाहुलेय	५	४
बाह्लिक	७६	४
	१४३	३
बाह्लीक	६४	१२
	८६	४
	११३	
बाह्य	१३९	१
बिड	८७	४
बिडाल	५०	
बिडौजस्	५	४
बिन्दु	२५	
बिन्दुजालक	७५	३

दः	पृष्ठम्	श्लोकः
म्ब	१०	१५
म्बिका	४६	१३९
ल	२३	१
लेशय	२३	८
ल्व	३६	३२
बिस	२८	४२
बिसकण्ठिका	५१	२५
बिसप्रसून	२८	४१
बिसिनी	२८	३९
बिस्त	९१	८६
बीज	१५	२८
	५९	६२
बीजकोश	२८	४३
बीजपूर्	४१	७८
बीजाकृत	८३	८
बीज्य	६६	२
बीभत्स	२१	१७
	२१	१९
	१३५	२३५
बुक	५१	८१
बुक्का	५९	६४
बुद्ध	२	१३
	१०७	१०८
बुद्धि	१५	१
बुद्बुद	१४१	१९
बुध	११	२६
	६६	५
	१२३	१००

शब्दः	पृष्ठम्	श्लोकः
बुधित	१०७	१०८
बुध्न	३५	१२
बुभुक्षा	८८	५४
बुभुक्षित	९९	२०
बुस	८५	२२
बुस्त	१४३	३४
बृंहित	८१	१०७
बृषी	७०	४६
बृहत्	१०३	६०
बृहतिका	६४	११७
बृहती	४२	९३
	१२०	७५
बृहत्कुक्षि	५७	४४
बृहद्भानु	६	२८
बृहस्पति	११	२४
बोधकर	८१	९७
बोधिद्रुम	३५	२०
बोल	९२	१०४
ब्रध्न	११	२८
ब्रह्मचारिन्	६६	३
	७०	४३
ब्रह्म	३७	४१
ब्रह्मत्व	७१	५२
ब्रह्मदर्भा	४७	१४५
ब्रह्मदारु	३७	४१
ब्रह्मन्	२	१६
	१२४	११४

शब्दः	पृष्ठम्
ब्रह्मपुत्र	२४
ब्रह्मबन्धु	१२३
ब्रह्मबिन्दु	७०
ब्रह्मभूय	७१
ब्रह्मयज्ञ	६७
ब्रह्मवर्चस	७०
ब्रह्मसायुज्य	७१
ब्रह्मसू	३
ब्रह्मसूत्र	७१
ब्रह्माञ्जली	७०
ब्रह्मासन	७०
ब्राह्म	१४
	७१
ब्राह्मण	६६
ब्राह्मणयष्टिका	४२
ब्राह्मणी	४२
ब्राह्मण्य	११२
ब्राह्मी	४
	१७
	४६
	भ.
भ	१०
भक्त	८७
भक्षक	९९
भक्षित	१०८
भक्ष्यकार	८५
भग	६०
	११५

	पृष्ठम्	श्लोकः
र	५८	५६
	२	१३
	५६	२९
	२५	५
	८५	२०
	१४०	८
	८३	७
ान	७४	२४
	७७	६१
	८७	४५
क	२०	१३
	२०	१३
की	४४	११४
ळ	३९	६३
	४२	९१
	१४ ८८	२५ ५९
ुम्भ	७५	३२
ारु	३८	५३
र्णी	३७	३६
ला	४७	१५३
ुस्तक	४८	१६०
व	४०	६७
श्री	६५	१३१
सन	७५	३१
	२१	२१
कर	२१	२०

शब्दः	पृष्ठम्	श्लोकः
भयद्रुत	१०१	४२
भयानक	२१ २१	१७ २०
भर	७	७०
भरण	९७	३९
भरण्य	९७	३९
भरण्यभुज	९९	१९
भरद्वाज	५०	१५
भर्ग	४	३६
भर्तृ	५६ ११९	३५ ५९
भर्तृदारक	२०	१२
भर्तृदारिका	२०	१३
भर्त्सन	१८	१४
भर्मन्	९१ ९६	९४ ३८
भल्लातकी	३७	४२
भल्लुक	४९	३
भल्लूक	४९	४
भव	४ १३३	३७ २०६
भवन	३१	५
भवानी	५	४०
भविक	१४	२६
भवितृ	१००	२९
भविष्णु	१००	२९
भव्य	१४	२६

शब्दः	पृष्ठम्	श्लो
भषक	९५	
भस्त्रा	९६	
भस्मगन्धिनी	४४	१
भस्मगर्भा	३९	
भा	१२	
भाग	९१	
भागधेय	१५ ७४	
भागिनेय	५६	
भागीरथी	२७	
भाग्य	१५ १२८	 १
भाजन	८६	
भाण्ड	८६ ११७	
भाद्र	१४	
भाद्रपद	१४	
भाद्रपदा	११	
भानु	११ १२ १२३	 १
भामिनी	५३	
भार	९१	
भारत	२९	
भारती	१७	
भारद्वाजी	४४	१
भारयष्टि	९६	

शब्दानुक्रमणिका.

ब्दः	पृष्ठम्	श्लोकः
ारवाह	९४	१५
ारिक	९४	१५
ार्गव	११	२५
ार्गवी	४८	१५८
ार्गी	४२	८९
ार्या	५४	६
ार्यापती	५७	३८
ाव	२० २१ १३३	१२ २१ २०८
मावित	६५ ८७ १०७	१३४ ४६ १०४
ावुक	१४	२६
ाषा	१७	१
ाषित	१७ १०७	१ १०७
ाव्य	१४३	३१
ास्	१२	३४
ास्कर	११	२८
ास्वत्	११	२९
मेक्षा	१०८ १३४	६ २२५
मेक्षु	७०	४२
मित्त	१०	१६
त्ति	३१	४
दा	१०८	५

शब्दः	पृष्ठम्	श्लोकः
भिदुर	६	५१
भिन्दिपाल	८०	९१
भिन्न	१०५ १०७	८२ १००
भिषज्	५८	५७
भिस्सटा	८७	४९
भिस्सा	८७	४८
भी	२१	२१
भीति	२१	२१
भीम	४ २१	३७ २०
भीरु	५३ १००	३ २६
भीरुक	१००	२६
भीलुक	१००	२६
भीषण	२१	२०
भीष्म	२१	२०
भीष्मसू	२७	३१
भुक्त	१०८	१११
भुग्न	१०४ १०६	७१ ९१
भुज	६०	८०
भुजग	२३	६
भुजङ्ग	२३	६
भुजङ्गभुज्	५२	३०
भुजङ्गम	२३	६
भुजङ्गाक्षी	४४	११५

शब्दः	पृष्ठम्
भुजशिरस्	६०
भुजान्तर	६०
भुजिष्य	९५
भुवन	२३ २५ २९
भू	२९
भूत	२ १०७ १२०
भूतकेश	९३
भूतकेशी	४०
भूतात्मन्	१२३
भूतावास	३९
भूति	४ ११९
भूतिक	११३
भूतेश	४
भूदार	४९
भूदेव	६६
भूनिम्ब	४६
भूप	७२
भूपदी	४०
भूभृत्	११९
भूमन्	१३९
भूमि	२९
भूमिजम्बुका	३७ ४४

	पृष्ठम्	श्लोकः
क्र	८३	१
	१०३	६३
	१०३	६३
	१०३ १३०	६३ १८३
ता	४६	१४३
य	४९	५
ा	४०	६९
	३८	४६
	६२	१०१
	६२	१००
	१००	२९
ा	४९	१६७
	३३	४
	४६ ५१ ५२	१३४ १६ २९
ज	४७	१५१
	७५	३२
ा	५२	२८
	९४	१५
	९६	२८
ज्र	९४	१५
	९५	१७
	९६	३८
	८	७१
	२६	२४

शब्दः	पृष्ठम्	श्लोकः
भेकी	२७	२४
भेद	७४ ७४	२० २१
भेदित	१०७	१००
भेरी	२०	६
भेषज	५८	५०
भैक्ष	७१	४७
भैरव	२१	१९
भैषज्य	५८	५०
भोग	११४	२३
भोगवती	१२०	७०
भोगिन्	२४	८
भोगिनी	५४	५
भोजन	८८	५५
भोस्	१३८	७
भौम	११	२५
भौरिक	७२	७
भ्रंश	७४	२३
भ्रकुंस	२०	२१
भ्रकुटि	२३	३७
भ्रम	१५ २५ १०९	४ ७ ९
भ्रमर	५२	२९
भ्रमरक	६२	९६
भ्रमि	१०९	९
भ्रष्ट	१०७	१०४
भ्रष्टयव	८७	४७

शब्दः	पृष्ठम्	श्लो
भ्राजिष्णु	६२	१
भ्रातरौ	५६	
भ्रातृज	५६	
भ्रातृजाया	५६	
भ्रातृभगिन्यौ	५६	
भ्रातृव्य	१२७	१
भ्रात्रीय	५६	
भ्रान्ति	१५	
भ्राष्ट्र	८५	
भ्रुकुंस	२०	
भ्रुकुटि	२३	
भ्रू	६२	
भ्रूकुंस	२०	
भ्रूकुटि	२३	
भ्रूण	५७ ११७ १२६	 १३
भ्रेष	७४	२
	म	
मकर	२६	२
मकरध्वज	३	२
मकरन्द	३५	१
मकुष्टक	८४	१
मकूलक	४७	१४
मक्षिका	५२	२
मख	६३	१
मगध	८३	

शब्दः	पृष्ठम्	श्लोकः
घवन्	५	४५
ङ्क्षु	१३८	२
ङ्गल	१४	२५
मङ्गल्यक	८४	१७
मङ्गल्या	६५	१२७
मचर्चिका	१४	२७
मज्जा	३५	१२
मञ्ज	६६	१३८
मञ्जरि	३५	१३
मञ्जिष्ठा	४२	९०
मञ्जीर	६३	१०९
मञ्जु	१०२	५२
मञ्जुल	१०२	५२
मञ्जूषा	९६	३०
मठ	३१	८
मड्डु	२०	८
मणि	४	३०
	९१	९३
मणिक	८६	३१
मणिवन्ध	६१	८१
मण्ड	३८	५१
	८७	४९
मण्डन	६२	१०२
	१००	२९
मण्डप	३२	९
मण्डल	९	६
	१०	१५
	१२	३२

शब्दः	पृष्ठम्	श्लोकः
मण्डलक	५८	५४
मण्डलाग्र	८०	८९
मण्डलेश्वर	७२	२
मण्डहारक	९४	१०
मण्डित	६२	१००
मण्डीरी	४२	९१
मण्डूक	२६	२४
मण्डूकपर्ण	३९	५६
मण्डूकपर्णी	४२	९१
मण्डर	९२	९८
मतङ्गज	७५	३४
मतल्लिका	१४	२७
मति	१५	१
मत्त	७५	३६
	१००	२३
	१०७	१०२
मत्तकाशिनी	५३	४
मत्सर	१३०	११३
मत्स्य	२६	१७
मत्स्यण्डी	८७	४३
मत्स्यपित्ता	४१	८६
मत्स्यवेधन	२६	१६
मत्स्याक्षी	४६	१३७
मत्स्यात्खग	१३४	२१९
मत्स्याधानी	२६	१६
मथित	८८	५३

शब्दः	पृष्ठम्
मद	७५
	१०९
	१२२
मदकल	७५
मदन	३
	३८
	४१
मदस्थान	९७
मदिरा	९७
मदिरागृह	३१
मदोत्कट	७५
मद्गु	५२
मद्गुर	२६
मद्य	९७
मधु	१३
	९३
	९७
	१२३
मधुक	४३
मधुकर	५२
मधुक्रम	९७
मधुद्रुम	३६
मधुप	५२
मधुपर्णिका	३७
	४२
मधुपर्णी	४१
मधुमाक्षिका	५२

	पृष्ठम्	श्लोकः
का	४३	१०९
	१६	९
	१३१	१९२
	४६	१४२
	४१	८३
	४३	१०७
	४७	१५२
	४३	१०५
	३	२०
	५२	२९
	९७	४१
	५२	२९
	३६	३१
	४१	८४
	३६	२८
	४६	१४२
	३६	२७
	९३	१०७
	३६	२८
	४१	८४
	६०	७९
	१२८	१६१
	३०	७
	१९	१
	३०	७
	६०	७९

शब्दः	पृष्ठम्	श्लोकः
मध्यमा	५४	८
	६१	८२
मध्याह्न	१२	३
मध्वासव	९७	४१
मनःशिला	९३	१०८
मनस्	१५	३१
मनसिज	३	२७
मनस्कार	१५	२
मनाक्	१३८	८
मनित	१०७	१०८
मनीषा	१५	१
मनीषिन्	६६	५
मनु	१४३	३८
मनुज	५३	१
मनुष्य	५३	१
मनुष्यधर्मन्	८	७३
मनोगुप्ता	९३	१०८
मनोजवस	९९	१३
मनोज्ञ	१०२	५२
मनोरथ	२२	२७
मनोरम	१०२	५२
मनोहत	१०१	४१
मनोह्वा	९३	१०८
मन्तु	७४	२६
मन्त्र	१२९	१६७
मन्त्रव्याख्याकृत्	६७	७
मान्त्रिन्	७२	४

शब्दः	पृष्ठम्	श्लोक
मन्थ	९०	७४
मन्थदण्डक	९०	७
मन्थन्	९०	७४
मन्थनी	९०	७४
मन्थर	७८	७२
मन्थान	९०	७४
मन्द	९५	१८
	१२२	९
मन्दगामिन्	७८	७
मन्दाकिनी	६	५३
मन्दाक्ष	२१	२
मन्दार	६	५४
	३६	२६
	४१	८१
मन्दिर	३१	५
मन्दुरा	३१	७
मन्दोष्ण	१२	३५
मन्द्र	१९	२
मन्मथ	३	२६
	३५	२९
मन्या	५९	६५
मन्यु	२२	२५
	१२८	१५४
मन्वन्तर	१४	२
मय	९०	७५
मयु	८	७५
मयुष्टक	८४	१

शब्दानुक्रमणिका.

शब्दः	पृष्ठम्	श्लोकः
मयूख	१२	३३
	११४	१८
मयूर	४४	१११
	५२	३०
मयूरक	४१	८८
	९२	१०१
मरकत	९१	९२
मरण	८२	११६
मरीच	८६	३६
मरीचि	११	२७
	१२	३३
मरीचिका	१२	३५
मरु	२९	५
	१२९	१६३
मरुत्	७	६६
	९	२
मरुत	११९	५९
मरुत्वत्	५	४५
मरुन्माला	४६	१३३
मरुबक	३८	५२
	४१	७९
मर्कट	४९	३
मर्कटक	५०	१३
मर्कटी	३८	४८
	४१	८७
मर्त्य	५३	१
मर्दनु	११०	२२
मर्दळ	२०	८
मर्मन्	१४३	३०
मर्मर	१९	२३
मर्मस्पृश्	१०५	८३
मर्यादा	७४	२६
मल	५९	६५
	१३२	१९७
मलदूषित	१०३	५५
मलयज	६५	१३१
मलयू	३९	६१
मलिन	१०३	५५
मळिनी	५५	२०
मलिम्लुच	९५	२५
मळीमस	१०३	५५
मल्ल	१४२	२१
मल्लक	१४३	३७
मल्लिका	४०	६९
मल्लिकाक्ष	५१	२४
मल्लिगन्धि	६५	१२७
मसी	१४१	१०
मसूर	८४	१७
मसूरविदला	४३	१०९
मसृण	८७	४६
मस्कर	४८	१६१
मस्करिन्	७०	४२
मस्तक	६२	९५
मास्तिष्क	५९	६५
मस्तु	८८	५४
मह	२३	
महत्	१०३	
महती	११९	
महस्	१३५	
महाकन्द	४७	
महाकुल	६६	
महाङ्ग	९०	
महाजाळी	४४	
महादेव	४	
महाधन	६३	
महानस	८५	
महामात्र	७२	
महारजत	९१	
महारजन	९२	
महारण्य	३४	
महाराजिक	२	
महारौरव	२४	
महाशय	९८	
महाशूद्री	५४	
महाश्वेता	४३	
महासहा	४०	
	४६	
महासेन	५	
महिला	५३	
महिलाह्वया	३८	
महिष	४९	
महिषी	५४	

पृष्ठम्	श्लोकः
२९	३
७२	१
३३	१
३४	५
२६	२१
११	२५
९८	३
४५	१२४
४	३३
८८	६१
२८	३९
९८	३
९८	३
४३ ४७ ८६	१०० १४८ ३८
३ १३९	२९ ११
५९ १४२	६३ २२
५७	४४
११७	४२
९४	१४
९३	१०७
८१ ९३	९७ २
४० ४२	७१ ९६

शब्दः	पृष्ठम्	श्लोकः
माघ	१३	१५
माघ्य	४०	७३
माठर	१२	३१
माढी	१४०	८
माणवक	५७ ६३	४२ १०६
माणव्य	११२	४१
माणिक्य	१४३	३१
माणिमन्थ	८७	४२
मातङ्ग	९५ ११४	१९ २१
मातरापितरौ	५६	३७
मातरिश्वन्	७	६५
मातलि	५	४९
मातापितरौ	५६	३७
मातामह	५६	३३
मातुल	४१ ५६	७८ ३१
मातुलपुत्रक	४१	७८
मातुलानी	५६ ८५	३० २०
मातुलाहि	२३	६
मातुली	५६	३०
मातुलुङ्गक	४१	७८
मातृ	४ २१ ५६ ८९	३८ १४ २९ ६६

शब्दः	पृष्ठम्	श्लोकः
मातृष्वसेय	५५	२१
मातृष्वस्रीय	५५	२५
मात्रा	१०३ १३०	६२ १७८
माद	१०९	१२
माधव	३ १३	१८ १६
माधवक	९७	४१
माधवी	४०	७२
माध्वीक	९७	४१
मान	२१	२२
मानव	५३	१
मानस	१५	३१
मानसौकस्	५१	२३
मानिनी	५३	३
मानुष	५३	१
मानुष्यक	११२	४२
माया	९४	११
मायाकार	९४	११
मायादेवीसुत	२	१५
मायु	५९	६२
मायूर	५३	४३
मार	३	२६
मारजित्	२	१३
मारण	८२	११४
मारिष	२१	१४
मारुत	७	६६

शब्दः	पृष्ठम्	श्लोकः
मार्कव	४७	१५१
मार्ग	१३ ३०	१४ १५
मार्गण	८० १०२ १११	८७ ४९ ३०
मार्गशीर्ष	१३	१४
मार्गित	१०७	१०५
मार्जन	३६	३३
मार्जना	६४	१२१
मार्जार	५०	६
मार्जिता	८७	४४
मार्तण्ड	११	२९
मार्दङ्गिक	९४	१३
मार्ष्टि	६४	१२१
मालक	३९	६२
मालती	४०	७२
माला	६५	१३५
मालाकार	९३	५
मालातृणक	४९	१६७
मालिक	९३	५
मालुधान	२३	६
मालूर	३६	३२
माल्य	६५	१३५
माल्यवत्	३३	३
माषपर्णी	४६	१३८
माषीण	८३	७

शब्दः	पृष्ठम्	श्लोकः
माघ्य	८३	७
मास	१३	१२
मासर	८७	४९
मासिक	६९	३१
मास्म	१३९	११
माहिष्य	९३	३
माहेयी	८९	६६
मितंपच	१०२	४८
मित्र	११ ७३ ७३ १२९	३० ९ १२ १६७
मिथस्	१३७	२५६
मिथुन	५३	३८
मिथ्या	१३९	१५
मिथ्यादृष्टि	१५	४
मिथ्याभियोग	१८	१०
मिथ्याभिशंसन	१८	१०
मिथ्यामति	१५	४
मिश्रेया	४३	१०५
मिसि	४३ ४७	१०५ १५२
मिहिका	१०	१८
मिहिर	११	२९
मीढ	१०६	९६
मीन	२६	१७
मीनकेतन	३	२६

शब्दः	पृष्ठम्
मुकुट	६२
मुकुन्द	३
मुकुर	६६
मुकुल	३५
मुक्तकञ्चुक	२३
मुक्ता	९१
मुक्तावली	९३
मुक्तास्फोट	२६
मुक्ति	१६
मुख	३२ ६१
मुखर	१०१
मुखवासन	१६
मुख्य	७० १०३ १४२
मुण्ड	५७ १४३
मुण्डित	५७ १०५
मुण्डिन्	९४
मुद्	१४
मुदिर	९
मुद्गपर्णी	४४
मुद्गर	८०
मुधा	१३८
मुनि	२ ७०

पृष्ठम्	श्लोकः
२	१४
२०	५
३	२३
४५	१२३
१०६	८८
६०	७६
३७	३९
१०९	१४
८५	२५
३	२५
४४	११९
५०	१२
१०२	४५
४८	१५९
४८	१५९
१३८	१
१८	१६
१३	११
९९	१३
१०२	४८
१०६	९५
५९	६७
५८	५६
१०६	९६
१०२	४८
८२	१०९
५९	६१

शब्दः	पृष्ठम्	श्लोकः
मूर्च्छित	५९	६१
	१२१	८२
मूर्त	५९	६१
	१०५	७६
मूर्ति	६०	७१
	११९	६६
मूर्तिमत्	१०५	७६
मूर्द्धन्	६२	९५
मूर्द्धाभिषिक्त	७२	१
	११९	६१
मूर्वा	४१	८३
मूल	३५	१२
	१३२	२००
मूलक	४८	१५७
मूलकर्मन्	१०८	४
मूलधन	९०	८०
मूल्य	९०	७९
	९७	३९
मूषक	५०	१२
मूषा	९६	३३
	१४३	३८
मूषिकपर्णी	४१	८८
मूषित	१०६	८८
मृग	५०	८
	१११	३०
	११४	२०
मृगणा	१११	३०
मृगतृष्णा	१२	३५

शब्दः	पृष्ठम्	श्लोकः
मृगदंशक	९५	२१
मृगधूर्तक	४९	५
मृगनाभि	६५	१२९
मृगवधाजवि	९५	२१
मृगबन्धनी	९५	२६
मृगमद	६५	१२९
मृगया	९५	२३
मृगयु	९५	२४
मृगरोमज	६३	११४
मृगव्य	९५	२३
मृगशिरस्	११	२३
मृगशीर्ष	११	२३
मृगाङ्क	१०	१४
मृगादन	४९	९
मृगित	१०७	१०५
मृगेन्द्र	४९	९
मृजा	६४	१२९
मृड	४	३४
मृडानी	५	४०
मृणाल	२८	४२
मृणाली	१४०	७
मृत्	२९	४
मृत	८२	११७
	८३	३
मृतस्नात	९९	१९
मृत्तालक	४५	१३९

शब्दः	पृष्ठम्	श्लोकः
मृत्तिका	२९	४
मृत्यु	८२	११६
मृत्युंजय	४	३४
मृत्क्षा	२९	४
मृत्स्ना	२९	४
	४५	१३१
मृदङ्ग	२०	५
मृदु	१०५	७८
	१२२	९४
मृदुत्वच्	३८	४६
मृदुल	१०५	७१
मृद्वीका	४३	१०७
मृध	८१	१०४
मृषा	११९	१५
मृषार्थक	१९	२१
मृष्ट	१०३	५६
मेकलकन्यका	२७	३२
मेखला	६३	१०८
	८०	९०
मेघ	९	६
मेघज्योतिस्	९	१०
मेघनादानुलासिन्	५२	३०
मेघनामन्	४८	१५९
मेघनिर्घोषा	९	८
मेघपुष्प	२५	५
मेघमाला	९	८
मेघनाहव,	५	४८

शब्दः	पृष्ठम्	श्लोकः
मेचक	१६	१४
	५२	३४
मेढ्र	६०	७६
	९०	७६
मेदक	९७	४२
मेदस्	५९	६४
मेदिनी	२९	३
मेदुर	१००	३०
मेधा	१५	२
मेधि	८४	१५
मेध्य	१०३	५५
मेनकात्मजा	५	४१
मेरु	६	५३
मेलक	१११	२९
मेष	११	२७
	९०	७६
मेषकम्बल	९३	१०७
मेह	५८	५६
मेहन	६०	७६
मैत्रावरुणि	१०	२०
मैत्री	१४३	३९
मैत्र्य	१४३	३९
मैथुन	७२	५७
	१२५	१२२
मैरेय	९७	४२
मोक्ष	१६	७
	३७	३९

शब्दः	पृष्ठम्
मोघ	१०५
मोघा	३८
मोचक	३६
मोचा	३८
	४४
मोदक	१४३
मोरट	९३
मोरटा	४१
मोषक	९५
मोह	८२
मौक्तिक	९१
मौद्गीन	८३
मौन	६९
मौरजिक	९४
मौर्वी	७९
मौलि	१३१
मौष्टा	१४०
मौहूर्त	७३
मौहूर्तिक	७३
म्लिष्ट	१९
म्लेच्छदेश	३०
म्लेच्छमुख	९२

य

शब्दः	पृष्ठम्
यकृत्	५९
यक्ष	३
	८

पृष्ठम्	श्लोकः
६५	१३३
६५	१२७
८	७२
५८	५१
६७	८
१७	३
६७	१३
३५	२२
६९	२७
६७	८
१३८	३
१३८	३
७०	४४
७०	४४
१३८	९
१०२	४८
१३९	१५
१३९	१४
१३९	१५
७३	१३
१३९	१४
८८	५७
१३९	१२
१०८	२
७७	५९
११९	५९

शब्दः	पृष्ठम्	श्लोकः
यम	७	६२
	७१	४९
	११०	१८
यमराज्	७	६२
यमुना	२७	३२
यमुनाभ्रातृ	७	६२
ययु	७६	४५
यव	८४	१५
यवक्य	८३	७
यवक्षार	९३	१०८
यवफल	४८	१६१
यवस	४९	१६७
यवागू	८७	५०
यवाग्रज	९३	१०८
यवानिका	४७	१४५
यवास	४२	९१
यवीयस्	५७	४३
यव्य	८३	७
यशःपटह	२०	६
यशस्	१८	११
यष्टि	१४३	१८
यष्टिमधुक	४३	१०९
यष्टृ	६७	८
याग	६७	१३
याचक	१०२	४९
याचनक	१०२	४९
याचना	६९	३२

शब्दः	पृष्ठम्	श्लोकः
याचित	८३	३
याचितक	८३	४
याच्ञा	६९	३२
	१०८	६
याजक	६८	१७
यातना	२४	३
यातयाम	१२७	१४५
यातु	७	६४
यातुधान	७	६४
यातृ	५६	३०
यात्रा	८०	९५
	१३०	१७६
यादःपति	२४	२
यादस्	२६	२०
यादसाम्पति	७	६५
यान	७३	१८
	७७	५८
यानमुख	७७	५५
याप्य	१०३	५४
याप्यमान	७७	५३
याम	१३	६
	११०	१८
यामिनी	१२	४
यामुन	९२	१००
यायजूक	६७	८
याव	६५	१२५
यावक	८४	१८

शब्दः	पृष्ठम्	श्लोकः
यावत्	१३७	२४७
यावन	६५	१२८
याष्टीक	७८	७०
यास	४२	९१
युक्त	७४	२४
युक्तरसा	४६	१४०
युग	५३	३८
	११५	२४
युगकीलक	८४	१४
युगन्धर	७७	५७
	१४३	३५
युगपत्	१४०	२२
युगपत्रक	३५	२२
युगपार्श्वग	८९	६३
युगल	५३	३८
युगान्तर	७७	५७
युग्म	५३	३८
युग्य	७७	५८
	८९	६४
युद्ध	८१	१०३
युद्ध	८१	१०६
युवति	५४	८
युवन्	५७	४२
युवराज	२०	१२
यूथ	५७	४१
यूथनाथ	७५	३५
यूथप	७५	३५

शब्दः	पृष्ठम्	श्लोकः
यूथिका	४०	७१
यूप	३७	४१
	१४३	३५
यूपक	१४२	१९
यूपकटक	६८	१८
यूपखण्ड	१२९	१६८
यूपाग्र	६८	१९
यूष	१४३	३५
योक्त्र	८४	१३
योग	११४	२२
योगेष्ट	९२	१०५
योग्य	४४	११२
योजन	१४३	३०
योजनवल्ली	४२	९१
योत्र	८४	१३
योद्धृ	७७	६१
योध	७७	६१
योधसंराव	८१	१०७
योनि	६०	७६
योषा	५३	२
योषित्	५३	२
यौतक	७४	२८
यौतव	९१	८५
यौवत	५५	२२
यौवन	५७	४०

र.

शब्दः	पृष्ठम्	श्लोकः
रंहस्	७	६८

शब्दः	पृष्ठम्
रक्त	१६
	५९
	६४
	१२०
रक्तक	४०
रक्तचन्दन	६५
	९३
रक्तपा	२६
रक्तफला	४६
रक्तसंध्यक	२८
रक्तसरोरुह	२८
रक्ताङ्ग	४७
रक्तोत्पल	२८
रक्षःसभ	१४२
रक्षस्	२
	७
रक्षित	१०७
रक्षिवर्ग	७२
रक्षण	१०९
रङ्कु	५०
रङ्ग	९२
रङ्गाजीव	९४
रचना	६६
रजक	९४
रजत	९२
	१२०
रजनी	१२
	४७

पृष्ठम्	श्लोकः
१२	६
१५	२९
५५	२१
८१	९८
१३५	१३२
५५	२०
९५	२७
६५	१३२
४२	९५
८१	१०४
१०९	८
११८	४९
४१	८८
७२	५८
३	२७
९१	९३
१२५	१२६
६	५३
२४	२
६१	८६
३६	३०
७६	५१
७७	५५
९३	४
९४	९
७७	५७
३६	२६

शब्दः	पृष्ठम्	श्लोकः
रथाङ्ग	७७	५५
	७७	५६
रथाङ्गाह्वयनामक	५१	२२
रथिक	७९	५६
रथिन्	७७	६०
	७९	७६
रथिन	७९	७६
रथ्य	७६	४६
रथ्या	३१	३
	७७	५५
रद	६१	९१
रदन	६१	९१
रदनच्छद	६१	९०
रन्ध्र	२३	२
रभस	१४२	२१
रमणी	५३	४
रम्भा	४४	११३
रय	७	६८
रल्लक	६४	११६
	१४१	१७
रव	१९	२२
रवण	१०१	३८
रवि	११	३१
रशना	६३	१०८
रश्मि	१२	३२
	१२६	१३८

शब्दः	पृष्ठम्	श्लोकः
रस	१६	७
	१६	९
	२१	१७
	९२	९९
	१३५	१२७
रसगर्भ	९२	१०२
रसज्ञा	६१	९१
रसना	६१	९१
रसवती	८५	२७
रसा	२९	२
	४१	८४
	४५	१२३
रसाञ्जन	९२	१०१
रसातल	२३	१
रसाल	३६	३३
	४८	१६३
	८७	४४
रसित	९	८
रसोनक	४७	१४८
रह	७४	२१
रहस्	७४	२२
रहस्य	७४	२३
राका	१३	८
राक्षस	७	६३
राक्षसी	५५	१२८
राक्षा	६५	१२५
राङ्कव	६३	१११
राज्	७२	१

शब्दः	पृष्ठम्	श्लोकः
राजक	७२	३
राजकशेरु	१३१	१८८
राजन्	२० ७२ १२४	१३ १ १११
राजन्य	७२	१
राजन्यक	७२	४
राजन्वत्	३०	१३
राजबला	४७	१५३
राजबीजिन्	६६	२
राजराज	८	७३
राजलिंग	१२२	९२
राजवंश्य	६६	२
राजवत्	३०	१३
राजवृक्ष	३६	२३
राजसदन	३२	१०
राजसभा	१४१	९
राजसूय	१४३	३१
राजहंस	५१	२४
राजादन	३७ ३८	३५ ४५
राजार्ह	६५	१२६
राजि	३४	४
राजिका	८४	१९
राजिल	२३	५
राजीव	२६ २८	१९ ४१
राज्यांग	७३	१८
रात्रि	१२	४
रात्रिचर	७	६४
रात्रिञ्चर	७	६४
सिद्धान्त	१५	४
राध	१३	१६
राधा	१०	२२
राम	३ ५० १२७	२४ ११ १४०
रामठ	८६	४०
रामा	५३	४
राम्भ	७०	४६
राल	६५	१२७
राशि	५३ १३४	४२ २१५
राष्ट्र	१३१	१८४
राष्ट्रिका	४२	९४
राष्ट्रिय	२०	१४
रासभ	९०	७७
रास्ना	४४ ४६	११४ १४०
राहु	११	२६
रिक्तक	१०३	५६
रिक्थ	९१	९०
रिङ्गण	२३	३६
रिपु	७३	१०
रिष्ट	११६	
रिष्टि	८०	
रीढा	२१	
रीण	१०६	
रीति	९२ ११९	
रीतिपुष्प	९२	
रुक्प्रतिक्रिया	५८	
रुक्म	९१	
रुक्मकारक	९४	
रुक्ष	१३५	
रुग्ण	१०६	
रुच्	१२	
रुचक	३८ ४१ ८७ ९३	
रुचि	१३ ११५	
रुचिर	१०२	
रुच्य	१०२	
रुज्	५८	
रुजा	५८	
रुत	१९	
रुदित	२२	
रुद्ध	१०६	

पृष्ठम्	श्लोकः
२ ४	१० ३७
५	४०
५९ १४२	६४ २२
५०	१२
१८	१८
२२	२६
४८	१५८
१६	७
५५	१९
९१ ९२ १२८	९१ ९६ १६१
७२	७
१०६	८९
७६	४८
८१	९८
८८	१२०
५९	६२
१०३ १२६	५४ १३२
३	२४
२७	३२
९१ १२९	९० १६६
२३	२

शब्दः	पृष्ठम्	श्लोकः
रोग	५८	५१
रोगहारिन्	५८	५७
रोचन	३८	४७
रोचनी	४३ ४७	१०८ १४६
रोचिष्णु	६२	१०१
रोचिस्	१२	३४
रोदन	६२	९३
रोदनी	४२	९२
रोदसी	१३५	२३०
रोदस्यौ	१३५	२३०
रोधस्	२५	७
रोप	८०	८७
रोमन्	६२	९९
रोमन्थ	१४१	१९
रोमहर्षण	२२	३५
रोमांच	२२	३५
रोष	२२	२६
रोहिणी	८९	६७
रोहित	१६ २६ ५०	१५ १९ १०
रोहितक	३८	४९
रोहिताश्व	६	५९
रोहिन्	३८	४९
रौद्र	२१ २१	१७ २०

शब्दः	पृष्ठम्	श्लोकः
रौमक	८७	४२
रौरव	२४	९
रौहिणेय	३ ११	२५ २६
रौहिष	४९ ५०	१६६ १०
	ल	
लकुच	३९	६०
लक्ष	८०	८६
लक्षण	१०	१७
लक्ष्मण	९९	१४
लक्ष्मणा	५१	२५
लक्ष्मन्	१० १२५	१७ १२४
लक्ष्मी	३ ४४ ७९	२८ ११२ ८२
लक्ष्मीवत्	९९	१८
लक्ष्य	२२ ८०	३३ ८६
लगुड	१४१	१८
लग्न	११	२७
लग्नक	९७	४४
लघु	७ ४६ ११५	६९ १३३ २८
लघुलय	४८	५२५

शब्दः	पृष्ठम्	श्लोकः
लङ्का	१४०	७
लङ्कोपिका	४६	१३३
लज्जा	२१	२३
लज्जाशील	१००	२८
लज्जित	१०६	९१
लट्वा	१४१	१०
लता	३४	९
	३४	११
	३८	५५
	४०	७२
	४६	१३३
	४७	१५०
लतार्क	४७	१४८
लपन	६१	८९
लपित	१७	१
	१०७	१०७
लब्ध	१०७	१०४
लब्धवर्ण	६६	६
लब्धानुज्ञ	६७	१०
लभ्य	७४	२४
लम्वन	६३	१०४
लम्बोदर	५	४२
लय	२०	९
ललना	५३	३
ललन्तिका	६३	१०४
ललाट	६२	९२
ललाटिका	६३	१०३

शब्दः	पृष्ठम्	श्लोकः
ललाम	१२७	१४४
ललामक	६५	१३५
ललित	२२	३१
लव	१०३	६२
	११०	२४
लवङ्ग	६५	१२५
लवण	१६	९
	८६	४१
	१४२	२३
लवणोद	२५	२
लवन	११०	२४
लवित्र	८४	१३
लशुन	४७	१४९
लस्तक	७९	८५
लाक्षा	६५	१२५
	१४१	१०
लाक्षाप्रसाद	३७	४१
लाङ्गल	८४	१३
लाङ्गल	८४	१३
लाङ्गलदण्ड	८४	१४
लाङ्गलपद्धति	८४	१४
लाङ्गलिकी	४४	११८
लाङ्गली	४४	१११
लाङ्गूल	७६	५०
लाजा	८७	४७
लाञ्छन	१०	१७
लाभ	९०	८०

शब्दः	पृष्ठम्
लामज्जक	४८
लालसा	२२
	१३५
लाला	५९
लालाटिक	११३
लात्र	५२
लासिका	२०
लास्य	२०
लिकुच	३९
लिक्षा	१४१
लिखित	७३
लिङ्गवृत्ति	७१
लिपि	७३
लिपिकर	७३
लिप्त	१०६
लिप्सा	२२
लिबि	७३
लीढ	१०८
लीला	२२
	२२
	१३२
लुठित	७६
लुब्ध	१००
लुब्धक	९५
लुलाय	४९
लूता	५०

पृष्ठम्	श्लोकः
१०७	१०३
७६	५०
१	८
७३	१५
५	४६
३४	४
९४	६
१०३	६२
८४	१२
८८	५६
२९	६
११२	२
२	१३
१४३	३२
३३	२
२	१६
६२	९३
४४	१११
३६	३३
१०	२०
९५	२५
६२	९९
४६	१३४
१०४	७४
१३३	२०६
१००	२२

शब्दः	पृष्ठम्	श्लोकः
लोलुभ	१००	२२
लोष्ट	८४	१२
लोष्टभेदन	८४	१२
लोह	६५ ९२ ९२ १४२	१२६ ९८ ९९ २३
लोहकारक	९४	७
लोहपृष्ठ	५१	१६
लोहल	१०१	३७
लोहाभिसार	८०	९४
लोहित	१६ ५९	१५ ६४
लोहितक	९१	९२
लोहितचन्दन	६४	१२४
लोहिताङ्ग	११	२५
व.		
व	१३८	९
वंश	४८ ६६ १३४	१६० १ २१५
वंशरोचना	९३	१०९
वंशिक	६५	१२६
वक्तव्य	१२८	१६०
वक्तृ	१०१	३५
वक्त्र	६१	८९
वक्र	१०४	७१

शब्दः	पृष्ठम्	श्लोकः
वक्षस्	६०	७८
वंक्षण	६०	७३
वङ्ग	९२	१०६
वचन	१७	१
वचनेस्थित	१००	२४
वचस्	१७	१
वचा	४३	१०२
वज्र	६ ४३ १३१	५१ १०५ १८५
वज्रनिर्घोष	९	१०
वज्रपुष्प	४०	७६
वज्रिन्	५	४६
वञ्चक	४९ १०२	५ ४७
वञ्चित	१०१	४१
वञ्जुल	३६ ३६ ३९	२७ ३० ६४
वट	३६	३२
वटक	१४१	१७
वटी	९५	२७
वडवा	७६	४६
वडवानल	६	६०
वड्	१०३	६१
वणिक्	९०	७८
वणिकपथ	११८	५२

शब्दः	पृष्ठम्	श्लोकः
वाँणज्या	९०	७९
वण्टक	९१	८९
वत्स	६० ८८ १३५	७८ ६२ २२७
बत्सक	३९	६६
वत्सतर	८८	६२
वत्सनाभ	२४	११
वत्सर	१३ १४	१३ २०
वत्सल	९९	१४
वत्सादनी	४१	८२
वद	१०१	३५
बदन	६१	८९
वदान्य	९८ १२८	६ १६१
वदावद	१०१	३५
बध	८२	११५
बध्य	१०२	४५
वन्ध्य	३४	७
बन्ध्या	८९	६९
वध्री	९६	३१
बधू	४६ ५३ ५४ १२३	१३३ २ ९ १०२
वन	२५ ३४ १२५	३ १ १२६

शब्दः	पृष्ठम्	श्लोकः
वनातिक्तिका	४१	८५
वनप्रिय	५१	१९
वनमाक्षिका	५२	२७
वनमालिन्	३१	२१
वनमुद्ग	८४	१७
वनशृङ्गाट	४२	९९
वनसमूह	३४	४
वनस्पति	३४	६
वनायुज	७६	४५
बनिता	५३ १२०	२ ७४
वनीयक	१०२	४९
वनौकस्	४९	३
बन्दा	४१	८२
वन्दारु	१००	२८
वन्या	३४	४
वपा	२३ ५९	२ ६४
वपुस्	६०	७०
वप्र	३१ ८४ ९२	३ ११ १०५
वमथु	५८ ७५	५५ ३७
बमि	५८	५५
वयस्	१३५	२३१

शब्दः	पृष्ठम्
वयस्था	३९ ४६ ४७
वयस्य	५७ ७३
वयस्या	५४
वर	६४ १०९ १३०
वरटा	५१ ५२
वरण	३१ ३६
वरण्ड	१४१
वरत्रा	७६ ९६
बरद	९८
वरवर्णिनी	५३ ८६
वराङ्ग	११५
बराङ्गक	४६
वराटक	२८ ९५ १४३
वरारोहा	५३
बराशि	६४
वराह	४९

	पृष्ठम्	श्लोकः
	१०७	१०२
	६९	३५
त	१०७	१०२
	९२	९७
	१०८	१११
	४३	१००
	१३६	२२६
	७ ९ ३६	६५ २ २५
	९७	३९
	७७	५७
	७९	७८
	१०३	५७
	९५	२३
	५३	४१
	१३५	२३१
	५९	६८
	६६ ७६ ११७	१ ४२ ४८
	६५ १४३	१३३ ३८
	१०८	११०
	७०	४३
	५२ ११३	३५ ११
	८३ १००	१ २९

शब्दः	पृष्ठम्	श्लोकः
वर्तनी	३०	१५
वर्ति	६५	१३३
वर्तिका	५२	३५
वर्तिष्णु	१००	२९
वर्तुल	१०४	६९
वर्त्मन्	३० १२४	१५ १२१
वर्धक	४२	९०
वर्धकि	९४	९
वर्धन	१०० १०९	२८ ७
वर्धमान	३८	५१
वर्धमानक	८६	३२
वर्धिष्णु	१००	२८
वर्मन्	७८	६४
वर्मित	७८	६५
वर्य	१०३	५७
वर्या	५४	७
वर्वणा	५२	२६
वर्ष	९ २९ १३४	११ ६ २२४
वर्षवर	७३	९
वर्षा	१४	१९
वर्षाभू	२६	२४
वर्षाभ्वी	२७	२४
वर्षीयस्	५७	४३

शब्दः	पृष्ठम्	श्लोकः
वर्षोपल	१०	१२
वर्ष्मन्	६० १२५	७० १२३
वलज	११६	३१
वलजा	११६	३१
वलभी	३२	१५
वलय	६३	१०७
वलयित	१०६	५०
वलीक	३२	१४
वलीमुख	४९	३
वल्क	३५	१२
वल्कल	३५	१२
वल्गित	७६	४८
वल्गु	१२७	१४५
वल्मीक	३०	१४
वल्लकी	१९	३
वल्लभ	१०२ १२६	५३ १३७
वल्लरि	३५	१३
वल्ली	३४	९
वल्लूर	५९	६३
वश	१०९	८
वशक्रिया	१०८	४
वशा	७५ ८९ १३४	३६ ६९ २१७

शब्दः	पृष्ठम्	श्लोकः
वशिक	१०३	५६
वशिर	४२ ८६	९७ ४१
वश्य	१००	२५
वषट्	१३८	८
वषट्कृत	६९	२७
वसति	११९	६७
वसन	६४	११५
वसन्त	१४	१८
वसा	५९	६४
वसु	२ ४१ ९१ १३५	१० ८१ ९० २२८
वसुक	४१ ८७	८० ४२
वसुदेव	३	२३
वसुधा	२९	३
वसुन्धरा	२९	३
वसुमती	२९	३
वस्तु	१४१	१३
वस्ति	६४	११४
वस्त्र	६४	११५
वस्त्रयोनि	६३	११०
वस्त्रवेश्मन्	६४	१२०
वस्न	९०	७९
वस्नसा	५९	६६

शब्दः	पृष्ठम्	श्लोकः
वह	८९	६३
वह्नि	६ ९	५७ २
वह्निसंज्ञक	४१	८०
वह्निशिख	९२	१०६
वा	१३७ १३८ १३९	२५० ९ १५
वाक्पति	१०१	३५
वाक्य	१७	२
वागीश	१०१	३५
वागुरा	९५	२६
वागुरिक	९४	१४
वाग्मिन्	१०१	३५
वाङ्मुख	१७	९
वाच्	१७	१
वाचंयम	७०	४२
वाचक	१७	२
वाचस्पति	११	२४
वाचाट	१०१	३६
वाचाल	१०१	३६
वाचिक	१८	१७
वाचोयुक्तिपटु	१०१	३५
वाज	८०	८७
वाजपेय	१४३	३१
वाजिदन्तक	४३	१०३

शब्दः	पृष्ठम्
वाजिन्	५२ ७६ १२३
वाजिशाला	३१
वाञ्छा	२२
वाटी	१४४
वाट्यालका	४३
वाडव	६ ६६ ७६
वाडवानल	६
वाडव्य	११२
वाणि	९६
वाणिज	९०
वाणिज्य	८३ ९०
वाणिनी	१२४
वाणी	१७
वातक	४७
वातकिन्	५९
वातपोथ	३६
वातप्रमी	५०
वातमृग	५०
वातरोगिन्	५९
वातायन	३२
वातायु	५०
वातूल	१३२

शब्दः	पृष्ठम्	श्लोकः
	१३२	१९६
	८८	६०
	२०	५
	२०	५
	३५	१५
	३६	२८
	६६	३
	४९	३
	३४	६
	३६	३०
	४५	१३१
	२७	२८
	१२७	१४५
	४	३५
	९	३
	५७	४६
	१०४	७०
	३०	१४
ना	५३	३
	५३	२
	७६	४६
	९६	२८
	५१	२०
ति	५०	१५
	४७	१५१
	४७	१४४
	७	६५

शब्दः	पृष्ठम्	श्लोकः
वायुसख	६	५९
वार्	२५	३
वार	५३	३९
	१२९	१६२
वारण	७५	३४
वारणबुसा	४४	११३
वारबाण	७७	६३
वारमुख्या	५५	१९
वारस्त्री	५५	१९
वाराही	४७	१५१
वारि	२५	३
वारिद	९	७
वारिपर्णी	२८	३८
वारिप्रवाह	३३	५
वारिवाह	९	६
वारी	७६	४३
वारुणी	११८	५२
वार्त	५८	५७
	१२०	७५
वार्ता	१७	७
	८३	१
	१२०	७५
वार्ताकी	४४	११४
वार्तावह	९४	१५
वार्धक	५७	४०
वार्धुषि	८३	५
वार्धुषिक	८३	५

शब्दः	पृष्ठम्	श्लोकः
वार्मण	११२	४
वार्षिक	४७	१५
वाल	६२	९
वालधि	७६	५
वालपाश्या	६३	१०
वालहस्त	७६	५
वालुक	४४	१२
वालुका	१२०	७
वाल्क	६३	११
वावदूक	१०१	३
वाशित	१९	२
वास	३१	६
वासक	४३	१०
वासगृह	३१	८
वासन्ती	४०	७
वासयोग	६५	१३४
वासर	१२	
वासव	५	४
वासस्	६४	११५
वासित	६५	१३४
	८७	४६
वासिता	१२०	७
वासुकि	२३	
वासुदेव	२	२
वासू	२१	१
वास्तु	३३	१

शब्दः	पृष्ठम्	श्लोकः
वास्तुक	४८	१५८
वास्तोष्पति	५	४७
वास्त्र	७७	५४
वाह	७६	४४
	९१	८८
वाहद्विषत्	४९	४
वाहन	७७	५८
वाहस	२३	५
वाहित्थ	७५	३९
वाहिनी	७९	७८
	७९	८१
	१२४	११२
वाहिनीपति	७७	६२
वि	५२	३३
विंशति	९०	८३
विकङ्कत	३७	३७
विकच	३४	७
विकर्तन	११	२९
विकलाङ्ग	५७	४६
विकस्वर	१००	३०
विकसा	४२	९०
विकसित	३४	८
विकस्वर	१००	३०
विकार	१०९	१५
विकासिन्	१००	३०
विकिर	५२	३३
विकीरण	४१	८०

शब्दः	पृष्ठम्	श्लोकः
विकुर्वाण	९८	७
विकृत	२१	१९
	५८	५८
विकृति	१०९	१५
विक्रम	८१	१०२
	१२७	१४१
विक्रय	९०	८३
विक्रयिक	९०	७९
विक्रान्त	७९	७७
विक्रिया	१०९	१५
विक्रेतृ	९०	७९
विक्रेय	९०	८२
विक्लव	१०२	४४
विक्षाव	१११	३७
विगत	१०७	१००
विगतार्तवा	५५	२१
विग्न	५७	४६
विग्रह	६०	७०
	८१	१०४
	११०	२२
विघस	६९	२८
विघ्न	११०	१९
विघ्नराज	५	४१
विचक्षण	६६	६
विचयन	१११	३०
विचार्चिका	५८	५३
बिचारणा	१५	२

शब्दः	पृष्ठम्
विचारित	१०७
विचिकित्सा	१५
विच्छन्दक	३२
विच्छाय	१४२
विजन	७४
	१२१
विजय	८२
विजिल	८७
विज्ञ	९८
विज्ञात	९८
विज्ञान	१६
विट्	५९
	८३
विट	१४१
विटङ्क	३२
विटप	३५
	१२५
विटपिन्	३४
विट्खदिर	३८
विट्चर	९५
विड	८७
विडङ्ग	४३
वितण्डा	१४१
वितथ	१९
वितरण	६९
वितर्दि	३२
वितस्ति	६१

	पृष्ठम्	श्लोकः
	३४	१२०
	१२४	११३
	४७	१४९
	४५	१२६
	८६	३७
	९२	१०१
	९१	९०
	९८	९
	१०७	९९
	१०८	५
	१४३	३२
	२५	१०
	३५	२०
	४३	११०
न्धा	४४	११५
	१०७	१०८
	१०८	१०९
	९	५
	७५	३७
	३६	३०
	१००	३०
	३६	३०
	१०७	९९
	४१	८४
	२	११
	९	९
	५८	५६
	८२	१११

शब्दः	पृष्ठम्	श्लोकः
विद्रुत	१०७	१००
विद्रुम	९१	९३
विद्रुमलता	४५	१२९
विद्वस्	६६	५
	१३५	२३५
विद्वेष	२२	२५
विधवा	५४	११
विधा	९६	३८
	१२३	१०१
विधातृ	२	१७
विधि	२	१७
	१५	२८
	७०	४०
	१२२	१००
विधिदर्शिन्	६८	१६
विधु	३	२२
	१०	१४
	१२२	९९
विधुत	१०७	१०७
विधुन्तुद	११	२६
विधुर	११०	२०
विधुवन	१०८	४
विधूनन	१०८	४
विधेय	१००	२४
विनयग्राहिन्	१००	२४
विना	१३८	३

शब्दः	पृष्ठम्	श्लोक
विनायक	२	१
	५	४
	११२	
विनाश	११०	२
विनाशोन्मुख	१०६	९
विनीत	७६	४
	१०१	२
विन्दु	१००	३
विन्ध्य	३३	
विन्न	१०७	९
	१०७	१०
विपक्ष	७३	११
विपञ्ची	२०	
विपण	९०	८
विपणि	३१	
	११८	५
विपत्ति	७९	७
विपथ	३०	९६
विपद्	७९	८
विपर्यय	१११	३३
विपर्यास	१११	३३
विपश्चित्	६६	५
विपाट्	२७	३३
विपादिका	५८	५
विपाशा	२७	३३
विपिन	३४	१
विपुल	१०८	६१

ब्दः	पृष्ठम्	श्लोकः
विप्र	६६ ६६	२ ४
विप्रकार	१०९	१५
विप्रकृत	१०१	४१
विप्रकृष्टक	१०४	६८
विप्रतीसार	२२	२५
विप्रयोग	११०	२८
विप्रलब्ध	१०१	४१
विप्रलम्भ	२३ ११०	३६ २८
विप्रलाप	१८	१६
विप्रश्निका	५५	२०
विप्रुष्	२५	६
विप्लव	१०९	१४
विबुध	१	७
विभव	९१	९०
विभाकर	११	२८
विभावरी	१२	४
विभावसु	६ ११ १३५	६० ३० २२६
विभीतक	३९	५८
विभूति	४	३९
विभूषण	६२	१०१
विभ्रम	२२ १२७	३१ १४२
विभ्राज्	६२	१०१

शब्दः	पृष्ठम्	श्लोकः
विमनस्	९८	१८
विमर्दन	१०९	१३
विमला	४६	१४३
विमातृज	५५	२५
विमान	६	५२
वियत्	८	२
वियद्गङ्गा	६	५३
वियम	११०	१८
वियात	१००	२५
वियाम	११०	१८
विरजस्तमस्	७०	४५
विरति	१११	३८
विरल	१०४	६६
विराज्	७२	१
विराव	१९	२३
विरिञ्चि	२	१७
विरूपाक्ष	४	३५
विरोचन	११ १२३	३० १०८
विरोध	२२	२५
विरोधन	११०	२१
विरोधोक्ति	१८	१६
विलक्ष	१००	२६
विलक्षण	१०८	२
विलम्बित	२०	९
विलम्भ	११०	२८
विलाप	१८	१६

शब्दः	पृष्ठम्
विलास	२२
विलीन	१०७
विलेपन	६५ ११०
विलेपी	८७
विवध	१२२
विवर	२३
विवर्ण	९४
विवश	१०२
विवस्वत्	११ ११८
विवाद	१७
विवाह	७१
विविक्त	७४ १२१
विविध	१०६
विविष्किर	५२
विवेक	७०
विव्वोक	२२
विश्	१३३
विशङ्कट	१०३
विशद	१६
विशर	८२
विशल्या	४१ ४६ १२८
विशसन	८२

शब्दः	पृष्ठम्	श्लोकः
	५	४३
	१०	२२
	१११	३२
	८२	११२
	१२२	९५
	१०३	६०
ा	६४	११४
वच्	३६	२३
	४८	१५६
	८०	८६
	३१	३
	६४	१२३
	६९	२९
	११०	२८
	९८	९
	२	१०
	८६	३८
	१०४	६५
	९५	२२
न्	१२३	१०९
ज	८६	३८
	३	२२
ा	२९	२
	२	१०
	३	२३
	२	१७

शब्दः	पृष्ठम्	श्लोकः
विश्वस्ता	५४	११
विश्वा	४२	९९
विश्वास	७४	२३
विषू	५९	६८
विष	२४	९
	१३४	२२३
विषधर	२३	७
विषमच्छद	३६	२३
विषय	१६	७
	३०	८
	१०९	११
	१२८	१५३
विषयिन्	१६	८
विषवैद्य	२४	११
विषा	४२	९९
विषाक्त	८०	८८
विषाण	११८	५६
विषाणी	४४	११९
विषुव	१३	१४
विषुवत्	१३	१४
विष्किर	५२	३३
विष्कम्भ	३२	१७
विष्टप	२९	६
विष्टर	१२९	१७०
विष्टरश्रवस्	२	१८
विष्टि	२४	३
विष्ठा	५९	६८

शब्दः	पृष्ठम्	श्लो
विष्णु	२	१
विष्णुक्रान्ता	४३	१०
विष्णुपद	८	
विष्णुपदी	२७	३
विष्णुरथ	४	३
विष्य	१०२	४
विष्वक्	१३९	१
विष्वक्सेन	३	१
विष्वक्सेनप्रिया	४७	१५
विष्वद्र्यक्	१०१	३
विसंवाद	२३	३
विसर	५३	३
विसर्जन	६९	२
विसर्पण	११०	२
विसार	२६	१
विसारिन्	१००	३
विसृत	१०५	८
विसृत्वर	१००	३
विसृमर	१००	३
विस्तर	११०	२
विस्तार	३५	१
	११०	२
विस्तृत	१०५	८
विस्फार	८२	१०
विस्फोट	५८	५
विस्मय	२१	१
विस्मयान्वित	१०८	२

शब्दानुक्रमणिका.

दः	पृष्ठम्	श्लोकः
स्मृत	१०५	८६
स्र	१६	१२
स्रम्भ	७४ १२६	२३ १३५
स्रसा	५७	४१
हग	५२	३२
हङ्ग	५२	३२
हङ्गम	५२	३२
हङ्गिका	९६	३०
हासित	२२	३५
हस्त	१०२	४३
हापित	६९	२९
हायस्	८ ५२	२ ३२
हायसं	८	२
हार	१०९	१६
ह्वल	१०२	४४
काश	१३४	२१५
चि	२५	५
णा	१९	३
णावाद	९४	१३
त	७६	४३
तंस	९५	२६
ति	७६	४३
तिहोत्र	६	५७
थी	३४ १२१	४ ८७

शब्दः	पृष्ठम्	श्लोकः
वीध्र	१०३	५५
वीनाह	२७	२७
वीर	२१ २१ ७८	१७ १८ ७७
वीरण	४८	१६४
वीरतर	४८	१६४
वीरतरु	३८	४५
वीरपत्नी	५५	१६
वीरपान	८१	१०३
वीरभार्या	५५	१६
वीरमातृ	५५	१६
वीरवृक्ष	३७	४२
वीराशंसन	८१	१००
वीरसू	५५	१६
वीरहन्	७१	५३
वीरुध्	३४	९
वीर्य	२२ ५९ १२८	२९ ६२ १५५
वीवध	१२२	९६
वृक	५०	७
वृकधूप	६५ ६५	१२८ १२९
वृकण	१०७	१०३
वृक्ष	३४	५
वृक्षभेदिन्	९६	३४

शब्दः	पृष्ठम्
वृक्षरुहा	४१
वृक्षवाटिका	३४
वृक्षादनी	४१ ९६
वृक्षाम्ल	८६
वृजिन	१४ १०४ १२३
वृत	१०६
वृति	३१ १०९
वृत्त	१०४ १०६ १२०
वृत्तान्त	१७ ११९
वृत्ति	८३ ८३ १२०
वृत्र	१२९
वृत्रहन्	५
वृथा	१३७ १३८
वृद्ध	४५ ५७ १२३
वृद्धत्व	५७
वृद्धदारक	४६

	पृष्ठम्	श्लोकः
मि	५९	६१
न्	५	४५
	५७	४०
	५४	१२
	७३ १०९	१९ ९
विका	८३	४
	१२१	८५
	८८	६१
	३५	१५
	१११	४०
	५३	४१
	५० २ ११३	९ ९ १६
	१०८	११२
	५० ११२	१४ ७
	११ १४ ४३ ४४ ८८ १३४	२७ २४ १०३ ११६ ५९ २२१
	६०	७६
	५०	६
	८	३७
	८८	५९
	९३	१

शब्दः	पृष्ठम्	श्लोकः
वृषस्यन्ती	५४	९
वृषा	५ ४१	४६ ८७
वृषाकपायी	१२८	१५६
वृषाकपी	१२५	१३०
वृष्टि	९	११
वृष्णि	९०	७६
वेग	११४	२०
वेगिन्	७८	७३
वेणि	६२	९८
वेणी	४०	६९
वेणु	४८	१६१
वेणुध्म	९४	१३
वेतन	९६	३८
वेतस	३६	२९
वेतस्वत्	३०	९
वेताल	१४२	२१
वेत्रवती	२७	३४
वेद	१७	३
वेदना	१०८	६
वेदि	६८	१८
वेदिक	३२	१६
वेध	१०९	८
वेधनिका	९६	३४
वेधमुख्य	४६	१३५
वेधस्	२ १३५	१७ २२९

शब्दः	पृष्ठम्	श्लो
वेधित	१०७	
वेपथु	२३	
वेमन्	९६	
वेला	१३२	१
वेल्ल	४३	१०
वेल्लज	८६	
वेल्लित	१०४ १०६	
वेश	३१	
वेशन्त	२७	
वेश्मन्	३१	
वेश्या	५५	१
वेश्याजनसमाश्रय	३१	
वेष	६२	
वेषवार	८६	
वेष्टित	१०६	
वेहत्	८९	
वै	१३८ १३९	 १
वैकक्षिक	६६	१
वैकुण्ठ	२	१
वैजनन	५७	
वैजयन्त	६	५
वैजयन्तिक	७८	
वैजयन्तिका	३९	६
वैजयन्ती	८१	
वैज्ञानिक	९८	

ब्दः	पृष्ठम्	श्लोकः
णत्र	३५	१८
णविक	९४	१३
णिक	९४	१३
णुक	७५	४१
तंसिक	९४	१४
तानिक	९४	१५
तरणी	२४	२
तालिक	८१	९७
वैदेहक	९३ ९०	३ ७८
वैदेही	४२	९६
वैद्य	५८	५७
वैद्यमातृ	४३	१०३
वैधात्र	६	५५
वैधेय	१०२	४८
वैनतेय	४	३२
वैनीतक	७७	५८
वैमात्रेय	५५	२५
वैयाघ्र	७७	५३
वैर	२२	२५
वैरनिर्यातन	८२	११०
वैरशुद्धि	८२	११०
वैरिन्	७३	१०
वैवाधिक	९४	१५
वैवस्वत	७	६३
वैशाख	१३ ९०	१६ ७४

शब्दः	पृष्ठम्	श्लोकः
वैश्य	८३	१
वैश्रवण	८	७३
वैश्वानर	६	५७
वैसारिण	२६	१७
वौषट्	१३८	८
व्यक्त	११९	६२
व्यक्ति	१५	३१
व्यग्र	१३१	१९०
व्यङ्गा	१३०	१७७
व्यजन	६६	१४०
व्यञ्जक	२१	१६
व्यञ्जन	१२४ १४२	११६ २३
व्यडम्बक	३८	५१
व्यत्यय	१११	३३
व्यत्यास	१११	३३
व्यथा	२४	३
व्यध	१०९	८
व्यध्व	३०	१६
व्यय	१०९	१७
व्यलीक	११३	१२
व्यवधा	१०	१२
व्यवसाय	१३३	२१३
व्यवहार	१७	९
व्यवाय	७२	५७
व्यसन	१२४	१२०
व्यसनार्त	१०२	४३

शब्दः	पृष्ठम्
व्यस्त	१०४
व्याकुल	१०२
व्याकोश	३४
व्याघ्र	४९ १०३
व्याघ्रनख	४५
व्याघ्रपाद्	३७
व्याघ्रपुच्छ	३८
व्याघ्राट	५०
व्याघ्री	४२
व्याज	२२ २२
व्याड	११७
व्याडायुध	४५
व्याध	९५
व्याधि	४५ ५८
व्याधिघात	३६
व्याधित	५८
व्यान	७
व्यापाद	१५
व्याप्य	४५
व्याम	६१
व्याल	२६ १३२
व्यालग्राहिन्	२४
व्यावृत्त	१०६

शब्दः	पृष्ठम्	श्लोकः
	११०	२२
	१७	१
	१२४	११८
	११६	३८
	११७	४५
ट	७८	६५
	९६	२८
	५३ ७९ १३६	३९ ७९ २३९
र्हिग	७९	७९
र	९४	७
ेश	४	३७
्	८	१
ान	६	५२
	९३	१११
	५३ ११५	३९ ३०
	६९ ८०	३६ ९५
	५८	५४
र्य	१३१	१८९
	७०	३८
	३४ ११९	९ ६७
्	६७	७
	९६	३३
व्रात	५३	३९
व्रात्य	७१	५४
व्रीडा	२१	२३
व्रीहि	८४ ८५	१५ २१
व्रैहेय	८३	६
	श	
शकट	७६	५२
शकल	१०	१६
शकुलिन्	२६	१७
शकुन	५२	३२
शकुनि	५२	३२
शकुन्त	५२ ११८	३२ ५८
शकुन्ति	५२	३२
शकुल	२६	१९
शकुलाक्षका	४८	१५९
शकुलादनी	४१ ४४	८६ १११
शकुलार्भक	२६	१७
शकृत्	५९	६७
शकृत्करि	८८	६२
शक्ति	७३ ८१ ११९	१२ १०२ ६६
शक्तिधर	५	४४
शक्तिहेतिक	७८	६९
शक्र	५ ३९	
शक्रधनुस्	९	
शक्रपादप	३८	
शक्रपुष्पिका	४६	
शक्ल	१०१	
शंकर	४	
शङ्कु	२६ ३४ ८७	
शङ्ख	८ २६ ४५ ११४	
शङ्खनख	२६	
शङ्खिनी	४५	
शची	५	
शचीपति	५	
शटी	४७	
शठ	१०२	
शणपर्णी	४७	
शणपुष्पिका	४३	
शणसूत्र	२६	
शत	९०	
शतकोटि	६	
शतद्रु	२७	
शतपत्र	२८	

ः	पृष्ठम्	श्लोकः
पत्रक	५१	१६
पदी	५०	१३
पर्वन्	४८	१६१
पर्विका	४३	१०२
	४८	१५८
तपुष्पा	४७	१५२
तप्रास	४०	७६
तमन्यु	५	४६
तमान	१४३	३४
तमूली	४३	१००
तयष्टिका	६३	१०५
तवीर्या	४८	१५९
तवेधिन्	४६	१४१
तहृदा	९	९
ताङ्ग	७६	५१
तावरी	४३	१०१
त्रु	७३	९
	७३	११
शनैश्चर	११	२६
शनैस्	१३९	१७
शपथ	१७	९
शपन	१७	९
शफ	७६	४९
शफरी	२६	१८
शबर	९५	२०
शबरालय	३३	२०
शबल	१७	१७

शब्दः	पृष्ठम्	श्लोकः
शबली	८९	६७
शब्द	१६	७
	१७	२
	१९	२२
शब्दग्रह	६२	९४
शब्दन	१०१	३८
शम	१०८	३
शमथ	१०८	३
शमन	७	६२
	६८	२६
शमनस्वसृ	२७	३२
शमल	५९	६७
शमित	१०६	९७
शमी	३८	५२
	८५	२३
शमीधान्य	८५	२४
शमीर	३८	५२
शम्पा	९	९
शम्पाक	३६	२३
शम्ब	६	५१
शम्बर	२५	४
	५०	१०
शम्बरारि	३	२७
शम्बरी	४१	८७
शम्बल	१४३	३४
शम्बाकृत	८४	९
शम्बूक	२६	२३

शब्दः	पृष्ठम्
शम्बली	५५
शम्भु	४
	१२६
शम्या	८४
शय	६१
शयन	२३
	६६
शयनीय	६६
शयालु	१०१
शयित	१०१
शयु	२३
शय्या	६६
शर	४८
	८०
शरजन्मन्	५
शरण	११८
शरद्	१४
	१४
	१२२
शरभ	५०
शरव्य	८०
शराभ्यास	८०
शरारि	५१
शरारु	१००
शराक	८
शरावती	
शरासन	
शरीर	६

২০৯৮

১৫০০>১৫০